वरदराजप्रणीता

मध्यसिद्धांतकौमुदी

विषमस्थलटिप्पणीसहिता

LIBRARY RULES.

I. Any one who shall lose, deface by writing or otherwise injure any book, shall pay the full cost of the book, or entire work, if there be more than one volume.

II. No student shall have more than one volume out of the Library at a time.

III. Students must not pass books from one to another, but must return them to the Librarian.

IV. Library books must not be used as class books.

V. Books must not be retained longer than 3 days or *one week*. They may be borrowed again, if not wanted by others.

VI. Text-books and books of reference shall not be taken home.

22

श्रीः

वरदराजप्रणीता

मध्यसिद्धांतकौमुदी ।

विषमस्थलटिप्पणपरिष्करणपुरःसरं
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा संशोधितम् ।

(तृतीयावृत्तिः ।)

सा च

मुम्बय्यां

पाण्डुरङ्ग जावजी

इत्येतैः स्वीये निर्णयसागरमुद्रणयन्त्रालये रामचंद्र येसु शेडगेद्वारा
मुद्रिता ।

शाकः १८४०; सन १९१९.

मूल्यं १। सपादरूप्यकः ।

Publisher—Pandurang Jawaji,
Printer—Ramchandra Yesu Shedge, } Nirnaya-Sagar Press, No. 23, Kolbhat Lane, Bombay.

भूमिका

ॐ नमः श्रीद्गुरुचरणारविन्दाभ्याम् ।

एवं किलोपाख्यायते—'पुरा किल भगवान्पाणिनिराचार्यो बाल्ये वयसि वर्तमानो भगवन्तमुपवर्षनामानमाचार्यं स्कन्दप्रसादसमासादितव्याकरणप्रभावनिरस्तसमस्ताज्ञानमुपासांचक्रे । तत्र चिरपरिचर्यारतस्याप्यस्य शुभोदर्कयापि तत्कालं कुटिलयेव गम्यमानयार्वाग्दृशां लोकातिगोत्कर्षभूमानमाधास्यन्त्या नियत्यावरुद्धप्रसरः सामन्त इव चक्रवर्त्युचिते पीठे विमलतरव्याकरणप्रभवेऽस्य चेतस्यलब्धावकाशो गुरूपदेशो रुषेवास्य मन्दमतितां शिष्यगणे प्राचारयत् । कदाचिदयमात्मसतीर्थ्येन वररुचिना सकृच्छ्रुतग्राहिणोपवर्षशिष्याग्रसरेणोपहसितो नितरामन्तर्दूयमानो निखिलविद्याप्रभवं भगवन्तमुमाकान्तमेवैकान्ततोऽज्ञाननाशायाराधयिष्य इति कृतमतिर्हिमवन्तं नगोत्तमं प्रातिष्ठत । अस्मिन्नेव काले सनकादयोऽपि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमद्वितीयमात्मतत्त्वं प्रत्यक्षीकर्तुकामाः सुदीर्घे तपसि वर्तमाना आसन् । पाणिनिरपि हिमवन्तमासाद्य दुश्चरेण तपसा समस्तलोकशंकरं शंकरं प्रासादयत् । अथ भगवान्महेश्वरो भक्तकल्पद्रुः सुचिरं दुश्चरं तपश्चरतां विभिन्नकामानामपि तेषामभिमतमेकेनैव यत्नेन युगपत्पूरयितुकामो डमरुवादनव्याजेन चतुर्दशसूत्रीमुपदिदेश । यां किलाक्षरसमाम्नायं ब्रह्मराशिमित्याक्षते । ब्रह्मप्रतिपादकोऽक्षरराशिरिति तस्यार्थः । तत्त्वं च नन्दिकेश्वरकृतकाशिकायां द्रष्टव्यम् । तत्र सर्वत्र सूत्रेष्वन्त्यं वर्णचतुर्दशं शब्दशास्त्रप्रवृत्तिरूपपाणिनीष्टसिद्ध्यर्थं समुपदिष्टम् । ततो महेश्वरानुग्रहेण समधिगताखिलविद्यामुखः पाणिनिर्वररुचिं वादायाहूय माहेश्वरेण बलेन वादसंग्रामशिरसि निर्जिगाय । ततो वररुचिरपि भगवन्तं महेश्वरं भृशं तपसः प्रसाद्य सर्वमपि पाणिनीयमध्यगच्छत् । भगवदा-

देशेन च तत्र वार्तिकमपि चकार । तच्च सूत्रादभ्यधिकं पाणिनीयस्य न्यूनतामावहतीति वीक्ष्य भगवान् पतञ्जलिर्भूत्वा पाणिनीयाष्टकव्याख्यानमिषेण निखिलवार्तिकजातस्य सूत्रसूचितार्थमूलकत्वं प्रदर्शयामास' इति । तदिदं भाष्यवार्तिकोपबृंहितं महाप्रज्ञानामपि दुरधिगमं पाणिनीयं व्याकरणमध्येतॄणां बालानामुपचिकीर्षया विद्वद्वरश्रीमद्भट्टोजीदीक्षितैः सिद्धान्तकौमुदीनामातिसुगमा सूत्रवृत्तिर्व्यरचि । तत एव च लोकेषु भूरिशः प्रयुज्यमानाञ्छब्दान्व्युत्पादयन्ति सूत्राण्युद्धृत्य तत्र दृष्टेनैव क्रमेण मध्यकौमुदीतिनाम्ना संगृहीतवान् श्रीवरदराजनामा पण्डितोऽल्पीयसा कालेनायासेन च लौकिकप्रयोगज्ञाननिर्वाहाय शास्त्रान्तराणि परिशीलयतां क्षिप्रं लौकिकेषु प्रयोगेषु व्युत्पित्सूनां च । सेयं मध्यसिद्धान्तकौमुदी अस्माभिः परिशोध्य विषमस्थलटिप्पणीनिवेशनेन परिष्कृताध्येतॄणामुपयोगक्षमा भूयादित्याशास्ते

पणशीकरोपाह्वो वासुदेवशर्मा.

श्रीः

मध्यसिद्धान्तकौमुदीस्थविषयक्रमः ।

॥ श्रीः ॥

मध्यसिद्धान्तकौमुदी ।

नत्वा[1] वरदराजः श्रीगुरून्[2] भट्टोजिदीक्षितान् ।
करोति पाणिनीयानां[3] मध्यसिद्धान्तकौमुदीम्[4] ॥ १ ॥

अइउण्[5] ।१। ऋऌक् ।२। एओङ्[6] ।३। ऐऔच् ।४। हयवरट् ।५। लण् ।६। ञमङणनम् ।७। झभञ् ।८। घढधष् ।९। जबगडदश् ।१०। खफछठथचटतव् ।११। कपय् ।१२। शषसर् ।१३। हल् ।१४। इति सूत्राण्यणादिसंज्ञार्थानि[7] ॥ इकारादिष्वकार[8] उच्चारणार्थः । लण्मध्ये[9] त्वित्सं-

---

१ मत्तस्त्वमुत्कृष्टः त्वत्तोऽहमपकृष्ट इत्याकारकज्ञानजनककरतलशिरःसंयोगानुकूलो व्यापारो नतिः, क्त्वाप्रत्ययार्थस्तदुत्तरकालिकत्वं तत्समानकर्तृकत्वं च । तथाच तादृशनमस्कारोत्तरा नमस्कारसमानकर्तृका च या मध्यसिद्धान्तकौमुदीविषयिणी कृतिस्तदाश्रयो ग्रन्थकर्तेति बोधः पर्यवस्यति । २ 'नास्ति तत्त्वं गुरोः परम्' इत्याद्युक्त्या गुरोरेव परमपदार्थत्वाद्गुरूनित्युक्तम् । ३ पाणिनिना प्रोक्तं पाणिनीयं, तदधीते विदन्ति वा पाणिनीयास्तेषाम् । ४ मध्यसिद्धान्तकौमुदीमिति । अत्यल्पाऽशेषाभ्यामन्ये मध्यभूताः सिद्धान्तास्तेषां प्रकाशिकाम् । ५ णादीनामनुबन्धः अणादिसंज्ञार्थः । ननु सवर्णयोरनयोः पृथग्ग्रहणं किमर्थं । नह्यकारादीनां सवर्णा उक्ता इति चेत् तयोः सावर्ण्यस्यानित्यत्वज्ञापनार्थमेवैतत् । तेन ऌ ३ प्लशिख इत्यत्र अनृत इति निषेधो न भवतीति । केचित्तु वार्तिकमदृष्ट्वा सूत्रकृतोऽप्रवृत्तेः पृथग्ग्रहणमित्याहुः । केचित्त्वकारादिस्वराणां चादिषु पाठात् 'चादयोऽसत्वे' इति निपातसंज्ञायां 'निपात एकाच्' इति प्रगृह्यते प्रकृतिभावान्न संधिरित्याहुः । ६ वर्णानामसंदिग्धत्वेन बोधाय संहिताया अविवक्षणादेतेषु न संधिरिति बोध्यम् । ७ अण् आदिर्यासां ता अणादयः, अणादयश्च ताः संज्ञाश्चेत्यणादिसंज्ञाः, अणादिसंज्ञाभ्य इमानीत्यस्वपदविग्रहः । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति नित्यसमासत्वात् । ८ हयवरट् इत्यादिषु । ९ उपदेशेऽजनुनासिक इदित्यनेन ।

ज्ञकः । हकारो द्विरुपात्तोऽयमटि शल्यपि वाञ्छता ॥ अर्हेणा[1]धुक्ष[2]दित्यत्र द्वयं सिद्धं भविष्यति ॥ **हलन्त्यम्**[3] ।१।३।३। उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम्[4] । सूत्रेष्वदृष्टं पदं सूत्रान्तरा[5]दनुवर्तनीयं सर्वत्र ॥ **अदर्शनं लोपः** ।१।१।६०। प्र[6]सक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥ **तस्य लोपः** ।१।३।९। तस्येतो लोपः स्यात् । णादयो[7]ऽणाद्यर्थाः ॥ **आदिरन्त्येन सहेता** ।१।१।७१। अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् । यथा अण् इति अइउवर्णानां संज्ञा । एवमच्, हल्, अल्, इत्यादयः ॥ **ऊकालोऽज्झ्रस्वदीर्घप्लुतः** ।१।२।२७। उश्च ऊश्च ऊ३श्च वः[8] । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स[9] प्रत्येकमुदात्तादिभेदेन त्रिधा ॥ **उच्चैरुदात्तः** ।१।२।२९। ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् ॥ **नीचैरनुदात्तः** ।१।२।३०। ताल्वादिषु सभागेषु स्थानेष्वधोभागे निष्पन्नोऽजनुदात्तसंज्ञः स्यात् ॥ **समाहारः स्वरितः** ।१।२।३१। उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सोऽच् स्वरितसंज्ञः स्यात् । स[10] नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥ **मुखनासिकावचनो[11]ऽनुनासिकः** ।१।१।८। मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम्—अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । ऌवर्णस्य द्वादश । तस्य दीर्घाभावात् । एचामपि द्वादश । तेषां

---

१ अर्हेणेत्यादावड्व्यवायेऽपि णत्वार्थमटि पाठः । २ अधुक्षदित्यादौ 'शल इगुपधात्' इत्यनेन च्लेः क्सादेशः । ३ हलि अन्त्यमित्येव विग्रहः सुवचः । ४ आद्याः शंकरपाणिन्यादयस्तैः कृतं डमरुमुखादिद्वारोच्चारणम् । ५ अष्टाध्याय्यां पूर्वपठितादन्यसूत्रात् । उपलक्षणमेतत् । क्वचिदपकर्षोऽपि बोध्यः । ६ शास्त्रतोऽर्थतो वा विद्यमानस्य । ७ अइउण् ऋऌक् इत्यादिष्वन्त्या ण् क् इत्यादयः अण् अक् इत्यादि प्रत्याहारार्थाः । ८ उकारत्रयस्य सवर्णदीर्घे कृते जसि परतो यणि वः इति रूपम् । ९ ह्रस्वदीर्घप्लुतानां पूर्वोक्तानामुकारत्रयाणाम् । १० ह्रस्वादिभेदेन उदात्तादिभेदेन चोक्तः । ११ उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्येति विग्रहः । मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यात् ।

ह्रस्वाभावात् ॥ **तुल्या[1]स्यप्रयत्नं सवर्णम्** ।१।१।९। ताल्वादिस्थानमाभ्यन्तर-प्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । (ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम्) । अकु[2]हविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि ॥ ॥ यत्नो द्विधा । आभ्यन्तरो बाह्यश्च । आद्यः पञ्चधा । स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शा[4]नाम् । ईषत्स्पृष्टमन्तस्थानाम् । ईषद्विवृतमूष्मणाम् । विवृतं स्वराणाम् । ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रिया[5]दशायां तु विवृतमेव । बाह्य[6]प्रयत्नस्त्वेकादशधा । विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति । खरो विवाराः[7] श्वासा अघोषाश्च । हशः संवारा नादा घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः । कादयो[9] मावसानाः स्पर्शाः । यणोऽन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ≍क≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः । ≍प≍फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः । अं अः इत्यचः परावनुस्वारविसर्गौ ॥ **अणुदित्सवर्णस्य चाप्रत्ययः** ।१।१।६९। अविधीय[10]मानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्रैवाण् [11]परेण णकारेण । कुचुटुतुपु एते उदितः । तदेवं अइत्यष्टा-

---

१ आस्ये भवमास्यं, आस्यं च प्रयत्नश्चास्यप्रयत्ने तुल्ये सदृशे आस्यप्रयत्ने यस्य । २ कु इति क ख ग घ ङ ग्राह्याः । ३ अत्र तपरकरणमसंदेहार्थं, तेन प्लुतस्यापि संग्रहः स्यात् । ४ कादयो मावसानाः स्पर्शा इति वक्ष्यमाणानाम् । ५ व्याकरणरीत्या शब्दसिद्धिपर्यन्तम् । ६ वर्णोत्पत्तेः पश्चाज्जातः । ७ विवारप्रयत्नवन्तः । एवमुत्तरत्रापि । यणप्रत्याहारान्तर्वर्तिनः । ९ लोकप्रसिद्ध्यपेक्षमिदम् । १० विधीयतेऽसौ विधीयमानः तथा न भवतीत्यविधीयमानः । तेन दाशरथिरित्यत्र 'अत इञ्' इत्यनेन त्रिमात्र ईकारो न भवतीति वेदितव्यम् । १२ अत्र 'ऋत उत्' इति सूत्रं लिङ्गम् । यदि हि पूर्वेण स्यात् तदा ऋकारस्योकारस्य च सवर्णाग्राहकत्वात्तपरकरणं व्यर्थं स्यात् ।

दशानां संज्ञा । तथैकारौकारौ । ऋकारस्त्रिंशतः । एवं ऌकारोऽपि । एचो द्वादशानाम् । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥ **परः संनिकर्षः संहिता** ।१।४।१०९। वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ॥ **हलोऽनन्तराः संयोगः**[2] ।१।१।७। अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥ **सुप्तिङन्तं पदम्** ।१।४।१४। सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥ **इति संध्युपयोगि संज्ञाप्रकरणम् ॥ १ ॥**

इको यणचि ।६।१।७७। इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते ॥ **तस्मिन्निति निर्दिष्टे पूर्वस्य** ।१।१।६६। सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य ज्ञेयम् ॥ **स्थानेऽन्तरतमः** ।१।१।५०। प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् उपास्य इति जाते ॥ **अनचि च** ।८।४।४७। अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धस्य द्वित्वम् ॥ **झलां जश् झशि** ।८।४।५३। झलां जश् स्यात् झशि परे । इति पूर्वधस्य दः ॥ **संयोगान्तस्य लोपः** ।८।२।२३। संयोगान्तं यत्पदं तस्य लोपः स्यात् ॥ **अलोऽन्त्यस्य** ।१।१।५२। षष्ठीनिर्दिष्टोऽन्त्यस्यादेशः स्यात् । इति यलोपे प्राप्ते । (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्ध्वरिः । धात्त्रंशः । लाकृतिः ॥ **एचोऽयवायावः** ।६।१।७८। एचः क्रमात् अय्, अव्, आय्, आव्, एते

---

१ ये त्वक्षरसमाम्नायिका अणस्त एव सवर्णानां ग्राहका भवन्ति । एवं च रेफहकारौ न कस्यापि ग्राहका भवतः । तत्सवर्णस्यान्यस्याभावादित्यवसेयम् । २ अल्पाक्षरसंज्ञायां कर्तव्यायां महासंज्ञाकरणमन्वर्थसंज्ञाज्ञापनार्थं । संयुज्यन्ते वर्णा अस्मिन्समुदाय इति । तत्फलं तु समुदाये संज्ञापर्याप्तिः नतु गुणादिवत्प्रत्येकं । तेन दृषद्भिभर्तीत्यादौ संयोगान्तलोपो न भवतीति ज्ञेयम् । ३ 'षष्ठीस्थाने योगा' इत्यनेन इकः स्थाने इत्यर्थो भवति । ४ निर् इत्यस्य नैरन्तर्यमर्थः । द्विशिरस्त्रोच्चारणार्थकः । तेनायमर्थः—अचि यण् भवतीत्युक्ते व्यवहितेऽव्यवहितेऽप्यचि प्राप्तेऽव्यवहित एवेति नियम्यते । ५ 'षष्ठी' इत्यनुवृत्त्या यत्र स्थाने षष्ठी तत्रैवेदं बोध्यम् । ६ प्रसङ्गः शास्त्रप्रसक्तिः । ७ अर्थात्प्रमाणानां मध्ये इत्यर्थो भवति । ८ स्थानषष्ठीनिर्दिष्टस्य य आदेश उच्यते सोऽन्त्यस्यालः स्थाने भवतीति ।

स्युरचि ॥ **यथासंख्यमनुदेशः समा[1]नाम्** ।१।३।१०। समसंबन्धी विधिर्यथासंख्यं स्यात् । हरये । विष्णवे । नायकः । पावकः ॥ **वान्तो यि प्रत्यये**।६।१।७९। [2]यादौ प्रत्यये परे ओदौतोरवावौ स्तः । [3]गव्यम् । [4]नाव्यम् । (अध्वपरिमाणे च) । [5]गव्यूतिः ॥ **धातोस्तन्निमित्तस्यैव** ।६।१।८०। यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्[6]यम् । [7]अवश्यलाव्यम् । तन्निमित्तस्य किम् । ओ[8]यते । औ[9]यत ॥ **क्ष[10]य्यजय्यौ शक्यार्थे** ।६।१।८१। यान्तादेशनिपातनार्थमिदम् । क्षय्यम् । जय्यम् । शक्यार्थे किम् । क्षेतुं जेतुं [11]योग्यं क्षेयं पापं जेयं मनः ॥ **क्रय्य[12]स्तदर्थे** ।६।१।८२। क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥ **अदेङ्गुणः** ।१।१।२। अदेङ् च गुणसंज्ञः स्यात् ॥ **तपरस्तत्कालस्य**।१।१।७०। तपरस्तात्परो वा उच्चार्यमाणो वर्णः

---

१ समानामिति संबन्धे षष्ठी । यथासंख्यमिति । उक्तक्रमेणेत्यर्थः । २ 'यस्मिन्विधिस्तदादावल्ग्रहण' इति परिभाषया यादावित्यर्थो भवति । ३ 'गोपयसोर्यत्' इति सूत्रेण गोशब्दात् विकार इत्यर्थे यत् प्रत्ययः । 'नौवयोधर्म–' इति सूत्रेण नौशब्दात्तार्यमित्यर्थे यत् । ५ 'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । ६ लुनातेः 'अचो यत्' इति यत् । 'सार्वधातुकार्धधातुकयोः' इति गुणश्च । ७ 'ओरावश्यके' इति ण्यत् । 'मयूरव्यंसकादयश्च' इति समासः । ८ आङ्पूर्वात् 'वेञ् तन्तुसंताने' इति धातोः कर्मणि लट्, यगात्मनेपदे, यजादित्वात् 'वचिस्वपियजादीनां किति' इत्यनेन संप्रसारणं पूर्वरूपं 'अकृत्सार्वधातुकयोः' इति दीर्घः 'आद्गुणः' इति सिद्धं रूपम् । अत्र गुणस्य परादिवद्भावेन धातोरेच्त्वेऽपि यादिप्रत्ययनिमित्तकत्वं नास्तीति भावः । ९ अत्रापि वेञः कर्मणि लङ् । यगादिकार्यं सर्वं प्राग्वत् । 'आडजादीनाम्' इति आडागमः । 'आटश्च' इति वृद्धिः । येषामित्संज्ञा कार्यानुसारतो दृश्यते त एवानुनासिका इति गुरुपरम्पराज्ञानेन कृतनिश्चया इत्यर्थः । १० 'क्षि क्षये' 'जि जये' इत्यनयोरेव ग्रहणं नतु 'क्षीष् हिंसायाम्' 'जै क्षये' इत्यनयोः, व्याख्यानात् 'शकि लिङ् च' इत्यनेन कृत्यप्रत्यः । ११ क्षेतुं योग्यं क्षेयं क्षेतुं जेतुं योग्यं जेयमित्यन्वयः । 'अर्हे कृत्यतृचश्च' इति अर्हार्थे यत् प्रत्ययः । १२ तदर्थे इति तस्मै प्रकृत्यर्थविनिमयायेदं तदर्थं । तत्र क्रय्य इति निपात्यते । १३ तत्रादिना तपरपदस्योभयपरत्वम् । तदेतद्दर्शयति–तेति ।

समकालस्यैव संज्ञा स्यात् ॥ **आद्गुणः** ।६।१।८७। अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥ **उपदेशेऽजनुनासिक इत्** ।१।३।२। उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ॥ **उरण् रपरः** ।१।१।५१। ऋ इति त्रिंशतः संज्ञेत्युक्तं तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णर्द्धिः । तवल्कारः ॥ **लोपः शाकल्यस्य** ।८।३।१९। अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ **पूर्वत्रासिद्धम्** ।८।२।१। अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् । हर इह । विष्ण इह । हरयिह । विष्णविह ॥ **वृद्धिरादैच्** ।१।१।१। आदैच वृद्धिसंज्ञः स्यात् ॥ **वृद्धिरेचि** ।६।१।८८। आदेचि परे वृद्धिरेकादेशः । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥ **एत्येधत्यूठ्सु** ।६।१।८९। अवर्णादेजाद्योरेत्येधत्यो- रूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । (स्वादीरेरिणोः) स्वैरम् । स्वैरी । स्वै- रिणी । (अक्षादूहिन्यामुपसंख्यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्येषु) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः । (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णमित्यादि ॥ **उपसर्गाः क्रियायोगे** ।१।४।५९। प्रादयः क्रियायोगे उपसर्ग- संज्ञाः स्युः । प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस । दुर् ।

---

१ उच्चारणसदृशकालस्यैव नत्वन्यस्येति हृदयम् । २ 'एकः पूर्वपरयोः' इत्यनुवर्तते । तदाह—पूर्वपरयोरेको गुणादेश इति । ३ प्रतिज्ञायते इति प्रतिज्ञा, अनुनासिकस्य भाव आनुनासिक्यम् प्रतिज्ञानुनासिक्यं येषामिति विग्रहः । ४ पाणिनिना प्रोक्तं पाणिनीयं, तदधीयते विदन्ति वा पाणिनीयाः । स्वदेशे वाक्यार्थशून्यत्वे सति परदेशैकवाक्यार्थतया स्वार्थबोधजनकोऽधिकारः । ६ 'इण् गतौ' 'एध वृद्धौ' इत्येतयोरित्यर्थः । 'वाह ऊठ्' इत्यनेन विहित ऊठ् । ७ योगः संबन्धः । स च धात्वर्थान्वयरूपो वेदनीयः । ८ ऊहः समूहः सोऽस्त्यस्याः सा ऊहिनी अक्षाणामूहिनी अक्षौहिणी परिमाणविशेषविशिष्टा सेना ।

वि । आङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप । एते प्रादयः ॥ **भूवादयो धातवः** ।१।३।१। क्रिया[1]वाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥ **उपसर्गादृति धातौ** ।६।१।९१। अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्च्छति ॥ **वा सुप्यापिशलेः** ।६।१।९२। आदुपसर्गादृकारादौ सुब्धातौ[2] परे वृद्धिर्वा । आपिशलिग्रहणं पूजार्थम् ॥ **अचो रहाभ्यां द्वे** ।८।४।४६। अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । इति प्राप्ते ॥ **शरोऽचि** ।८।४।४९। द्वे न । प्रार्षभीयति । प्रर्षभीयति ॥ **एङि पररूपम्** ।६।१।९४। आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः । प्रेजते । उपोषति ॥ **अचोऽन्त्यादि टि** ।१।१।६४। अचां[3] मध्ये योऽन्त्यः स आदिर्यस्य तद्टिसंज्ञं स्यात् । (शकन्ध्वादिषु[4] पररूपं वाच्यम्) (तच्च टेः) । शकन्धुः[5] । कर्कन्धुः[6] । कुलटा[7] । सीमन्तः केशवेशे । सीमान्तोऽन्यः । मनीषा[8] । हलीषा[9] । लाङ्गलीषा । पतञ्जलिः[10] । सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः । आकृतिगणोऽयम् । (एवे चानियोगे[11]) । क्वेव भोक्ष्यसे । अनियोगे किम् । तवैव । (ओत्वोष्ठयोः समासे वा) । स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥ **ओमाङोश्च** ।६।१।९५।

---

१ भूश्च वाश्च भूवौ, आदिश्च आदिश्च आदी, भूवौ आदी एषामिति विग्रहः । द्वितीये आदिशब्दः प्रकारे । तथाच वासदृशा ये भूप्रभृतयस्ते धातुसंज्ञका भवन्तीत्यर्थः । सादृश्यं च क्रियावाचकत्वरूपं ग्राह्यम् । २ सुबन्तात् 'तत्करोति तदाचष्टे' इत्याद्यर्थे णिजादिकृते 'सनाद्यन्ता धातवः' इत्यनेन धातुसंज्ञिताः सुब्धातवोऽवगन्तव्याः । ३ अच इति निर्धारणे षष्ठी । एकवचनं जात्यभिप्रायम् । तदेतदाह—अचां मध्य इति । ४ शकन्ध्वादिशब्देषु तत्सिद्ध्यनुगुणं पररूपं वाच्यमित्यर्थः । तदेतदाह—तच्च टेरिति । तच्च पररूपं टिसंज्ञकस्यैव स्यादित्यर्थः । ५ शकानां देशविशेषाणामन्धुः कूपः शकन्धुः । ६ कर्काणां राजविशेषाणामन्धुः कर्कन्धुः । ७ अटतीत्यटा । पचाद्यचि टाप् । कुलस्य अटा कुलटा । यदि तु कुलानि अटतीति विगृह्येत तदाहि कर्मण्यणि अणन्तान्ङीपि कुलाटीति स्यात् । ८ मनस ईषा मनीषा । ९ हलस्य ईषा हलीषा । 'ईषा लाङ्गलदण्डः स्यात्' इत्यमरः । १० पतन्तः अञ्जलयो यस्मिन् स पतञ्जलिः । ११ अनियोगोऽनिर्धारणम् ।

ओमि आङि चात् परे पररूपमेकादेशः स्यात् । शिवायोन्नमः । शिव आ इहि इति स्थिते । शिव एहि । शिवेहि ॥ **अकः सवर्णे दीर्घः** ।६।१।१०१। अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । (ऋति सवर्णे ऋ वा) । होतृकारः । होतॄकारः ॥ **एङः पदान्तादति** ।६।१।१०९। पदान्तादेङोऽति परे पूर्वरूपमेकादशः स्यात् । हरेऽव । विष्णोऽव ॥ **सर्वत्र विभाषा गोः** ।६।१।१२२। लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः[1] पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्र्[2]ग्वग्रं । पदान्तस्य किम् । गोः ॥ **अनेकाल् शित् सर्वस्य** ।१।१।५५। इति प्राप्ते ॥ **ङिच्च** ।१।१।५३। ङिदनेकालप्यन्तस्यैव स्यात् ॥ **अवङ् स्फोटायनस्य** ।६।१।१२३। पदान्ते एङन्तस्य गोरवङ् वा स्यादचि । गवाग्रम् । पदान्ते किम् । गवि ॥ **इन्द्रे च** ।६।१।१२४। गोरवङिन्द्रे । गवेन्द्रः । व्यवस्थितविभाषया । गवाक्षः ॥ **दूराद्धू[3]ते च** ।८।२।८४। दूरात्संबोधने वाक्यस्य टेः प्लुतो वा ॥

अथ प्रकृतिभावः ॥ **प्लुतप्रगृह्या अचि नित्यम्** ।६।१।१२५। एतेऽचि प्रकृत्या स्युः । आगच्छ कृष्ण ३ अत्र गौश्चरति ॥ **ह्रस्वं लघु** ।१।४।१०। **संयोगे गुरु** ।१।४।११। संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥ **दीर्घं च** ।१।४।१२। गुरु स्यात् ॥ **गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्** ।८।२।८६। प्लुतो वा । दे ३ वदत्त ३ । गुरोः किम् । वकारादकारस्य मा भूत् । अनृतः किम् । कृष्ण ३ । एकैकग्रहणं पर्यायार्थम् ॥ **ईदूदेद्द्विवचनं प्रगृह्यम्** ।१।१।११। ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । मणीवोष्ट्र[4]स्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥

---

१ प्रकृतिभावो नाम संधिकार्यरहितत्वम् । २ अत्र 'एकदेशविकृतमनन्यवत्' इति न्यायेन गोशब्दोऽस्त्येवेति ज्ञेयम् । ३ हूतमाह्वानं तच्च संबोधनमात्रस्योपलक्षणमित्याह—दूरात्संबोधने इति तत्त्वबोधिनी । ४ अत्र वृत्तिकारेण 'मणीवादीनां प्रतिषेधो वक्तव्यः' इति पठित्वा मणीव रोदसीव जंपतीवेत्युदाहृतम् । 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इत्ययं भारतप्रयोगः ।

अदसो मात् ।१।१।१२। अस्मात्[1]परावीदू[2]तौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत[3] ॥ **चादयोऽसत्त्वे** ।१।४।५७। अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥ **प्रादयः** ।१।४।५८। एतेऽपि तथा । (वस्तू[4]पलक्षणं यत्र सर्वनाम प्रयुज्यते ॥ द्रव्यमित्युच्यते सोऽर्थोऽभेद्यत्वेन विवक्षितः ॥) लिङ्गसंख्यान्वययोग्यं द्रव्यम् ॥ **निपात एकाजनाङ्** ।१।१।१४। एकोऽज् निपात आङ्वर्जः प्रगृह्यः । इ इन्द्रः । उ उमेशः । वाक्यस्मरणयोर[5]ङित् । आ एवं नु मन्यसे । आ एवं किल तत् । अन्यत्र ङित् । ईषदुष्णम् । ओष्णम् ॥ **ओत्** ।१।१।१५। ओदन्तो निपातः प्रगृह्यः । अहो ईशाः ॥ **संबुद्धौ शाकल्यस्येतावनार्षे** ।१।१।१६। संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्णविति । विष्ण इति ॥ **मय उञो वो वा** ।८।३।३३। मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् ॥ **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** ।६।१।१२७। पदान्ता इको ह्रस्वाः प्रकृत्या च वा स्युरसवर्णेऽचि । ह्रस्वविधिसामर्थ्यान्न स्वरसंधिः । चक्रि अत्र । चक्र्यत्र । पदान्ताः किम् । गौर्यौ । (न समा[6]से) । वाप्यश्वः ॥ **ऋत्यकः** ।६।१।१२८। ऋति परे पदान्ता अकः प्राग्वत् । ब्रह्म ऋषिः ब्रह्मर्षिः । पदान्ताः किम् । आर्च्छत्[7] ॥ **इति स्वरसंधिः** ॥

---

१ अदस्शब्दसंबन्धिनः । २ ननु 'संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायादेकारोऽप्यनुवर्तेत । सत्यम् । असंभवान्नानुवर्तनीयः । नहि अदसो मात् क्वाप्यकारः संभवतीति । ३ तथाच एकाराननुवृत्तितात्पर्यबोधकं माद्ग्रहणमिति । ४ अत्रोपलक्षणशब्दार्थः वक्तव्यांशैकदेशोच्चारणम् नतु अविद्यमानं सत् व्यावर्तकमिति । 'भू सत्तायाम्' सत्ताद्यर्थनिर्देशस्तूपलक्षणमित्यादावप्ययमेवार्थो बोध्यः । ५ आकारस्य आङश्च भेदं प्रदर्शयितुमाह—वाक्येति । 'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् । ६ ह्रस्वत्वं प्रकृतिभावश्च समासे न भवत इत्यर्थः । ७ 'ऋच्छ' इति धातोर्लङि आटि च आऋच्छत् इत्यवस्थायां 'आडजादीनाम्' इति वृद्धौ रूपमिदम् । पदान्ता इत्यनुक्तौ वृद्धिर्न स्यादित्यर्थः ।

स्तोः श्चुना श्चुः ।८।४।४०। सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः[1] ॥ हरिश्शेते[2] । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥ **शात्** ।८।४।४४। शात्परस्योक्तं न स्यात्[3] । विश्नः । प्रश्नः ॥ **ष्टुना ष्टुः** ।८।४।४१। स्तोः ष्टुना योगे ष्टुः । रामष्षीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥ **न पदान्ताट्टोरनाम्** ।८।४।४२। पदान्ताट्टवर्गात् परस्यानामः स्तोः ष्टुर्न । षट् सन्तः । षट् ते । पदान्तात्किम् ईट्टे । टोः किम् । सर्पिष्टमम् । (अनाम्नवतिनगरीणामुपसंख्यानम्) । षण्णाम् । षण्णवतिः । षण्णगर्यः ॥ **तोः षि** ।८।४।४३। न ष्टुत्वम् । सन्षष्ठः ॥ **झलां जशोऽन्ते** ।८।२।३९। पदान्ते झलां जशः स्युः । वागीशः । चिद्रूपम् ॥ **यरोऽनुनासिकेऽनुनासिको वा** ।८।४।४५। यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः । (प्रत्यये भाषायां नित्यम्) । तन्मात्रम्[4] । चिन्मयम् ॥ **तोर्लि** ।८।४।६०। परसवर्णः[5] । तल्लयः । विद्वाँल्लिखति । नस्यानुनासिको ल्ँः[6] ॥ **उदः स्थास्तम्भोः पूर्वस्य** ।८।४।६१। उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ॥ **तस्मादित्युत्तरस्य** ।१।१।६७। पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥ **आदेः परस्य** ।१।१।५४। परस्य यद्विहितं तत्तस्यादेर्बोध्यम्[7] । अघोषस्य महाप्राणस्य विवारस्य श्वासस्य सस्य तादृश एव थकारः ॥ **झरो झरि सवर्णे** ।८।४।६५। हलः परस्य झरो लोपो वा सवर्णे झरि ॥ **खरि च** ।८।४।५५। झलां चरः स्युः । इत्युदो दस्य तः । उत्थानम् । उत्तम्भनम् ॥ **झयो होऽन्यतरस्याम्** ।८।४।६२। झयः परस्य हस्य वा पूर्व-

---

१ स् च तुश्चानयोः समाहारः स्तुः । तस्य स्तोः । सौत्रं पुंस्त्वम् । तदेतदाह-सकारेति । श्चुना श्चुः इत्यादावप्येवं बोध्यम् । २ 'वा शरि' इति पाक्षिकत्वाद्विसर्जनीयस्य सः तस्य शेन योगे शः चवर्गयोगे तु रामश्चिनोति । तवर्गस्य तु चवर्गयोगे सच्चित् इत्यादि । शेन योगे तु तच्छिव इत्यादि वक्ष्यत्यग्रे । ३ तवर्गस्य चुत्वं न स्यादित्यर्थः । ४ तदेव तन्मात्रम् । ५ तवर्गस्य लकारे परे परसवर्णः स्यादिति वृत्तिः । ६ अनुनासिकाननुनासिकभेदेन यवला द्विधेत्युक्तत्वात् । ७ 'अलोऽन्त्यस्य' इत्यस्यापवादोऽयम् ।

सवर्णः । संवारस्य नादस्य घोषस्य महाप्राणस्य हस्य तादृशो वर्गचतुर्थः । वाग्घरिः । वाग्हरिः ॥ **शश्छोऽटि** ।८।४।६३। पदान्तात् झयः परस्य शस्य छो वा स्यादटि । तच्छिवः[1] । तच्शिवः । पदान्तात्किम् । विश्पशम् । (छत्वममीति वाच्यम्) । तच्छ्लोकेन ॥ **मोऽनुस्वारः** ।८।३।२३। मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे । पदस्य किम् । गम्यते ॥ **नश्चापदान्तस्य झलि**[4] ।८।३।२४। नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंसते । झलि किम् । मन्यते ॥ **अनुस्वारस्य यथि परसवर्णः** ।८।४।५८। शान्तः । अङ्कितः ॥ **वा पदान्तस्य** ।८।४।५९। त्वङ्करोषि । त्वं करोषि ॥ **मो राजि समः क्वौ** ।८।३।२५। क्विबन्ते[2] राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥ **हे मपरे वा** ।८।३।२६। मपरे हकारे मस्य मो वा । किम्ह्मलयति । किं ह्मलयति । (यवलपरे[3] यवला वेति वक्तव्यम्) । किं ह्यः, किँय्ह्यः, । किंह्वलयति । किँव्ह्वलयति किं ह्लादयति । किँल्ह्लादयति ॥ **नपरे नः** ।८।३।२७। नपरे हकारे मस्य नो वा । किन्ह्नुते । किं ह्नुते ॥ **ङः सि धुट्** ।८।३।२९। ङात्परस्य सस्य धुड् वा ॥ **आद्यन्तौ टकितौ** ।१।१।४६। टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः । षट्त्सन्तः । षट्सन्तः ॥ **ङ्णोः कुक् टुक् शरि** ।८।३।२८। वा स्तः । प्राङ्क्ष्षष्ठः । प्राङ्षष्ठः । सुगण्ट्षष्ठः । सुगण्षष्ठः ॥ **नश्च** ।८।३।३०। नान्तात्परस्य सस्य धुड्वा । सन्त्सः ॥ **शि तुक्** ।८।३।३१। नस्य पदान्तस्य शे तुक् वा । सञ्छम्भुः । सञ्च्शम्भुः । सञ्च्शम्भुः । सञ्शम्भुः । 'ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात्' ॥ **ङमो ह्रस्वादचि**

१ तद् शिव इति स्थिते दकारस्य श्चुत्वेन जकारे कृते तस्य 'खरि च' इति चर्त्वे अनेन शस्य छे तच्छिव इति निष्पन्नम् । २ 'येन विधिस्तदन्तस्य' विशेषणं तत् अन्ते यस्य तस्य संज्ञकं भवतीति क्वौ इत्यस्य क्विबन्त इत्यर्थः । तदेतदाह—क्वीति । ३ यवलाः परे यस्मात्स यवलपरस्तादृशे हकारे परे मस्य क्रमेण यवला भवन्तीत्यर्थः । ४ झीति सप्तमी पूर्वत्र कृताया नश्चेति पञ्चम्याः षष्ठीं कल्पयतीत्याह—नस्येति । ५ ङम् प्रत्याहारः, संज्ञायां च कृतं टित्वं सामर्थ्यात्संज्ञिभिः संबध्यते तेन यथासंख्यं ङुट्णुट्नुटः प्रवर्तन्ते । नित्यग्रहणं विस्पष्टार्थम् ॥

ङमुण्नित्यम् ।८।३।३२। ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुट् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥ **समः सुटि** ।८।३।५। समो रुः सुटि ॥ **अत्रानुनासिकः पूर्वस्य तु वा** ।८।३।२। अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा ॥ **अनुनासिकात्परोऽनुस्वारः**[१] ।८।३।४। अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः ॥ **खरवसानयोर्विसर्जनीयः** ।८।३।१५। खरि अवसाने च पदान्तस्य रेफस्य विसर्गः । (संपुंकानां सो वक्तव्यः) । सँस्कर्ता ॥ **पुमः खय्यम्परे** ।८।३।६। अम्परे खयि पुमो रुः । पुँस्कोकिलः । पुंस्कोकिलः ॥ **नश्छव्यप्रशान्** ।८।३।७। अम्परे छवि नान्तस्य पदस्य रुः ॥ **विसर्जनीयस्य सः**[२] ।८।३।३४। खरि । चक्रिँस्त्रायस्व । चक्रिंस्त्रायस्व । अप्रशान् किम् । प्रशान्तनोति । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः ॥ **नॄन्पे** ।८।३।१०। नॄनित्यस्य रुर्वा पे ॥ **कुप्वोः ≍क≍पौ च** ।८।३।३७। कवर्गे पवर्गे च परे विसर्गस्य ≍ क ≍ पौ स्तः । चाद्विसर्गः । नॄँ≍पाहि । नॄँः पाहि । नॄं≍पाहि । नॄंः पाहि । नॄन्पाहि ॥ **सोपदादौ** ।८।३।३८। विसर्गस्य सः स्यादपदाद्योः कुप्वोः । पयस्पाशम् । पयस्कल्पम् । यशस्काम्यति । (अनव्ययस्येति वाच्यम्) । प्रातःकल्पम् । (काम्ये रोरेवेति वाच्यम् ।) नेह । गीः काम्यति ॥ **इणः षः** ।८।३।३९। इणः परस्य विसर्गस्य षः स्यात् पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥ **कस्कादिषु च** ।८।३।४। एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यस्य तु सः । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालमित्यादि । आकृतिगणोऽयम् ॥ **तस्य परमाम्रेडितम्** ।८।१।२। द्विरुक्तस्य परमाम्रेडितं स्यात् ॥ **कानाम्रेडिते**[३] ।८।३।१२। कान्नकारस्य रुराम्रे-

---

१ अनुनासिकादिति ल्यब्लोपे पञ्चमी बोध्या, तदभिप्रायेणैवानुनासिकं विहाय इत्याद्यर्थः ।

२ अत्र 'सोपदादौ' इत्यतः सः 'इणः षः' इति सूत्रं चानुवर्तते । तथाच एष्विण इत्याद्यर्थः ।

३ कान् कानिति वाच्ये आम्रेडितग्रहणं यत्र द्विरुक्तिस्तत्रैव यथा स्यात् । इह माभूत् । कान् कान् पश्यसि । अत्र एकः किंशब्दः प्रश्ने, द्वितीयः क्षेपे । कान् कुत्सितान् पश्यसीत्यर्थः ।

डिते । काँस्कान् । कांस्कान् ॥ **छे च**[1] ।६।१।७३। ह्रस्वस्य छे तुक् । स्वच्छाया । शिवच्छाया ॥ **आङ्[2]माङोश्च** ।६।१।७४। तुक् छे । आच्छादयति । माच्छिदत् ॥ **दीर्घात्** ।६।१।७५। तुक् छे । म्लेच्छति ॥ **पदान्ताद्वा** ।६।१।७६। दीर्घात्पदान्ताच्छे तुग्वा । लक्ष्मीछाया । लक्ष्मीच्छाया ॥ **इति हल्संधिः** ॥

विसर्जनीयस्य सः ।८।३।३४। खरि । विष्णुस्त्राता ॥ **शर्[3]परे विसर्जनीयः** ।८।३।३५। शर्परे खरि विसर्गस्य विसर्गो न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः। **वा शरि** ।८।३।३६। शरि विसर्गस्य विसर्गो वा । हरिः शेते । हरिश्शेते । (खर्परे शरि वा विसर्गस्य लोपो वक्तव्यः) । हरिस्फुरति । हरिः स्फुरति ॥ **ससजुषो रुः** ।८।२।६६। प[4]दान्तस्य सस्य सजुष्[5]शब्दस्य च रुः स्यात् ॥ **अतो रोरप्लुतादप्लुते** ।६।१।११३। अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । शिवोऽर्च्यः । अतः किम् । देवा अत्र । अतीति किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुश्रोत३ अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यम् । दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुतेति किम् । तिष्ठतु पय अ३ग्निदत्त ॥ **हशि च** ।६।१।११४। तर्था । शिवो वन्द्यः ॥ **भोभगोअघोअपूर्वस्य योऽशि** ।८।३।१७। एतत्पूर्वस्य रोर्यादेशोऽशि । देवा इह । देवायिह । भोस् भगोस् अघोस् इति सान्ता निपाताः । तेषां रुत्वे यत्वे च कृते ॥ **व्योर्[7]लघुप्रयत्नतरः शाकटायनस्य** ।८।३।१८। अशि पदान्ते ॥ **ओतो गार्ग्यस्य** ।८।३।२०। ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य

---

१ छकारोत्तरवर्त्यकार उच्चारणार्थः । 'विदिभिदिच्छिदेः कुरच्' इति सूत्रनिर्देशात् । २ अत्र 'सहचरितासहचरितयोर्मध्ये सहचरितस्यैव ग्रहणम्' इति न्यायेन आङः साहचर्यात् माङपि अव्ययमेव ग्राह्यम् । ३ सत्वादेरपवादोऽयम् । शर् परः यस्मादिति बहुव्रीहिः । ४ पदान्तस्येत्यनुवृत्तं ससजूर्भ्यां विशेष्यते । विशेषणेन तदन्तविधिः । अन्तः 'पदान्तस्य सस्य सजुष्शब्दस्य' इति सिद्धम् । ५ तदन्तस्य पदस्येत्यर्थः । तेन 'सजुषौ, सजुष' इत्यत्रापि नातिव्याप्तिः । ६ पूर्वसूत्रवदप्लुतादतः परस्य रोरुः स्यात् । ७ वकारयकारयोः लघुप्रयत्नतरः लघूच्चारणतरः । आन्तरतम्याद्वस्य वः, यस्य यो ज्ञेयः ॥

यस्य नित्यं लोपः । भोअच्युत । लघुप्रयत्नपक्षे । भोयच्युत । पदान्तस्य किम् । तोयम् ॥ **हलि सर्वेषाम्** ।८।३।२२। भोभगोअघोअपूर्वस्य यस्य नित्यं लोपः स्याद्धलि । भोदेवाः । भगो नमस्ते । अघो याहि । देवा यान्ति ॥ **रोऽसुपि** ।८।२।६९। अह्नो रेफादेशो न तु सुपि । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्र अहन् इति रुत्वम् । (रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्) । अहो रूपम् । गतमहो रात्रिरेषा । एकदेशविकृतन्यायेनाहोरात्रः । अहोरथन्तरम् । (अहरादीनां पत्यादिषु वा रेफः) । विसर्गापवादः । अहर्पतिः । गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥ **रो रि** ।८।३।१४। रेफस्य रेफे परे लोपः ॥ **ढ्रलोपे पूर्वस्य दीर्घोऽणः** ।६।३।१११। ढरेफयोर्लोपनिमित्तयोः । पुना रमते । हरी रम्यः । शंभू राजते ॥ **ढो ढे लोपः** ।८।३।१३। लीढः । अणः किम् । तृढः । वृढः । मनस्‌रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥ **विप्रतिषेधे परं कार्यम्** ।१।४।२। तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥ **एतत्तदोः सुलोपोऽकोरनञ्समासे हलि** ।६।१।१३२। अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि नतु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असः शिवः । हलि किम् । एषोऽत्र ॥ **सोऽचि लोपे चेत्पादपूरणम्** ।६।१।

---

१ 'एकदेशविकृतमनन्यवद्भवति' एकदेशेन पुच्छेन विकृतः श्वा तद्भिन्नो न भवति यथा तथेत्यर्थः । २ ढश्च रश्च ढ्रौ तौ लोपयतीति ढ्रलोपः । णिजन्तात्कर्मण्यणि उपपदसमासः । अचीति विस्पष्टार्थम् । ३ तुल्यबलेति । द्वयोः क्वचिल्लब्धावकाशयोरेकत्र प्रयोगे युगपदसंभविकार्यसमर्पणे परं कार्यमित्यर्थः । ४ सिद्धासिद्धयोरतुल्यबलत्वेन 'विप्रतिषेधे—' इत्यस्याप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेवेति हृदयम् । यथाहुः—पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येति । ५ अत्र 'प्रकृतिवदनुकरणम्' इत्यस्य वैकल्पिकत्वात्त्यदाद्यत्वाभावो बोध्यः । ६ नञ्तत्पुरुषस्य पूर्वपदार्थप्राधान्येन तच्छब्दाद्यर्थस्योपसर्जनत्वात् त्यदाद्यत्वाभावेन हल्ङ्यादिलोपो दुर्वार इति शङ्काभिप्रायः । समाधानं तु इदमेव नञ्समासस्य उत्तरपदार्थप्राधान्ये ज्ञापकम् ।

१३४। स इत्यस्य सोर्लोपः स्यादचि । पादश्चेल्लोपे सत्येव पूर्येत । सैमामविड्ढिप्रभृतिम् । सैष दाशरथी रामः । इति विसर्गसन्धिः ॥ ४ ॥

अथाजन्ताः पुंलिङ्गाः ।

अर्थवदधातुरप्रत्ययः[1] प्रातिपदिकम् ।१।२।४५। धातुं प्रत्ययं प्रत्ययान्तं[2] च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥ **कृत्तद्धितसमासाश्च[3]** ।१।२।४६। कृत्तद्धितान्तौ समासाश्च तथा स्युः ॥ **स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप्** ।४।१।२। सु औ जस् प्रथमा । अम् औट् शस् द्वितीया । टा भ्यां भिस् तृतीया । ङे भ्यां भ्यस् चतुर्थी । ङसि भ्यां भ्यस् पञ्चमी । ङस् ओस् आम् षष्ठी । ङि ओस् सुप् सप्तमी ॥ **ङ्याप्प्रातिपदिकात्** ।४।१।१। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः ॥ **सुपः[4]** ।१।४।१०३। सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥ **द्व्येकयोर्द्विवचनैकवचने** ।१।४।२२। द्वित्वैकत्वयोरेते स्तः ॥ **विरामोऽवसानम्** ।१।४।११०। वर्णानामभावोऽवसानसंज्ञः स्यात् । रुत्वविसर्गौ । रामः । (अयोगवाहानामस्योपरि शर्षु चेति वाच्यम्) । यमानुस्वारविसर्गजिह्वामूलीयोपध्मानीया अयोगवाहाः । तेनेह विसर्गस्य यर्त्वादनचिचेति द्वित्वपक्षे रामः ॥ **सरूपाणामेकशेष[5] एकविभक्तौ** ।१।२।६४। एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥ **प्रथमयोः पूर्वसवर्णः** ।६।१।१०२। अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥ **नादिचि** ।६।१।१०४। आदिचि न पूर्वसवर्णदीर्घः ॥ वृद्धिरेचि । रामौ ॥ बहुषु

---

१ अधातुप्रत्ययावित्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थम् । अधातुरप्रत्यय इति पुंलिङ्गनिर्देशस्तु परवल्लिङ्गमित्युत्तरपदलिङ्गवत्त्वाद्बोध्यः । २ सूत्रे तत्रादिनोभयं विवक्षितमिति भावः । ३ अत्रार्थवदित्यनुवर्तते तत्सामर्थ्यात्तदन्तविधिरिति तत्त्वबोधिनी । ४ सुबिति प्रत्याहारो न सप्तमीबहुवचनम्, एकस्यानेकसंज्ञाविधानानर्थक्यात् । ५ इतरनिवृत्तिपूर्वकमवस्थानं शेषशब्दार्थः ॥

बहुवचनम् ।१।४।२१॥ **चुटू** ।१।३।७। प्रत्यय[1]याद्यौ चुटू इतौ स्तः ॥ **विभक्तिश्च** ।१।४।१०४। सुप्तिङौ विभक्तिसंज्ञौ स्तः ॥ **न विभक्तौ तुस्माः** ।१।३।४। विभक्तिस्थास्तुस्मा नेतः । इति सस्य नेत्वम् । रामाः ॥ **एकवचनं संबुद्धिः** ।६।२।४९। संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥ **यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्** ।१।४।१३। यः प्रत्ययो यस्मात्क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात् ॥ **एङ्ह्रस्वात्संबुद्धेः** ।६।१।६९। एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । हे राम । हे रामौ । हे रामाः ॥ **अमि पूर्वः**[2] ।६।१।१०७। अकोऽम्यचि पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥ **लशक्वतद्धिते** ।१।३।८। तद्धितवर्जप्रत्य[3]याद्या लशकवर्गा इतः स्युः ॥ **तस्मा[4]च्छसो नः पुंसि** ।६।१।१०३। पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि ॥ **अ[5]ट्कुप्वाङ्नुम्व्यवायेऽपि** ।८।४।२। अट् कवर्ग पवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात् समानपदे । इति प्राप्ते ॥ **पदान्तस्य**[6] ।८।४।३७। नस्य णो न । रामान् ॥ **टाङसिङसामिनात्स्याः** ।७।१।१२। अदन्ताट्टादीनामिनादयः स्युः । णत्वम् । रामेण ॥ **सुपि च** ।७।३।१०२। य[7]ञादौ सुप्यतोऽङ्गस्य दीर्घः । रामाभ्याम् ॥ **अतो भिस् ऐस्** ।७।१।९। अनेकाल्शित्सर्वस्य । रामैः ॥ **ङे[8]र्यः** ।७।१।१३। अतो-

---

१ 'आदिर्ञिटुडवः' इत्यत आदिः 'षः प्रत्ययस्य' इत्यतः प्रत्ययस्येति चानुवर्तते । २ प्रथमयोरिति पूर्वसवर्णदीर्घे प्राप्तेऽयमारम्भः । अत्र पूर्वसवर्ण इत्यनुवृत्त्यैव सिद्धे पूर्वग्रहणं व्यर्थमिति वाच्यम् । न रामं कुमारीमित्यादावान्तरतम्याद्द्विमात्रापत्तेः । ३ प्रत्ययाद्या इति लश्च शश्च कुश्चेति समाहारद्वन्द्वे लशक्विति नपुंसकम् । ४ तच्छब्देन संनिहितः पूर्वसवर्णदीर्घः परामृश्यते । दीर्घमात्रपरामर्शे तु एतान् गाः पश्येत्यत्रापि नत्वप्रसंगात् । ५ अत्र सूत्रे रषाभ्यामिति पञ्चमीनिर्देशाद्व्यवहितस्याप्राप्तौ वचनमिदमिति तत्त्वबोधिन्याम् । ६ अत्र सूत्रे अनन्तरस्येतिव्यवस्थापकन्यायाप्रवृत्तिर्बोध्या । अपदान्तस्येत्यनुवृत्त्यैतस्य भाष्ये प्रत्याख्यानात् । ७ यञीत्यनुवर्तते । अल्ग्रहणात्तदादिविधिरित्याह । ८ ङेरिति चतुर्थ्येकवचनस्य ग्रहणं नतु सप्तम्येकवचनस्य व्याख्यानात् । अत एव ङेराम् इत्यत्रास्याग्रहणम् समानाधिकरणे स्त्रियामित्यादिनिर्देशाच्च ।

ङ्गात्परस्य ङेर्यादेशः स्यात् ॥ **स्थानिवदादेशोऽनल्विधौ** ।१।१।५६। आदेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधौ । इति स्थानिवत्वात्सुपि चेति दीर्घः । रामाय । रामाभ्याम् ॥ **बहुवचने झल्येत्** ।७।३।१०३। झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः । रामेभ्यः ॥ **वावसाने** ।८।४।५६। अवसाने झलां चरो वा । रामात् । रामाद् । रामाभ्याम् । रामेभ्यः । रामस्य ॥ **ओसि च** ।७।३।१०४। अतोऽङ्गस्यैकारः । रामयोः ॥ **ह्रस्वनद्यापो नुट्** ।७।१।५४। ह्रस्वान्तान्नद्यन्तादाबन्ताच्चा[1]ङ्गात्परस्यामो नुडागमः ॥ **नामि** ।६।४।३। अजन्ताङ्गस्य दीर्घः । रामाणाम् । रामे । रामयोः । सुपि एत्वे कृते ॥ **आदेशप्रत्यययोः** ।८।३।५९। इण्कुभ्यां परस्यापदान्तस्यादेशः प्रत्ययावयवश्च यः सस्तस्य मूर्धन्यादेशः । ईषद्विवृतस्य सस्य तादृश एव षः । रामेषु । एवं कृष्णमुकुन्दादयः ॥ **सर्वादीनि**[2] **सर्वनामानि** ।१।१।२७। सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञानि स्युः । सर्व । विश्व । उभ । उभय । डतर । डतम । अन्य । अन्यतर । इतर । त्वत् । त्व । नेम । सम । सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् । तद् । यद् । एतद् । इदम् । अदस् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् । एते पञ्चत्रिंशच्छब्दाः सर्वादयः ॥ **जसः शी**[3] ।७।१।१७। अदन्तात्सर्वनाम्नो जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । सर्वे ॥ **सर्वनाम्नः स्मै** ।७।१।१४। अतः सर्वनाम्नो ङेः स्मै ॥ **ङसिङ्योः स्मात्स्मिनौ** ।७।१।१५। अतः सर्वनाम्न एतयोरेतौ स्तः । सर्वस्मात् । सर्वस्माद् ॥ **आमि सर्वनाम्नः सुट्** ।७।१।५२। अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । उभशब्दो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २ । तस्येह पाठोऽकजर्थः[4] । डतरडतमौ प्रत्ययौ । प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता

---

१ एतेन ह्रस्वनद्याप इति पञ्चमी नतु षष्ठीति स्फोटितम् । २ तद्गुणसंविज्ञानो बहुव्रीहिरयम् । अदः सर्वेषामिति लिङ्गात् । ३ दीर्घोच्चारणमुत्तरार्थम् । वारिणी । मधुनी । ४ अव्ययसर्वनाम्नामकच् प्राक्टेरित्युक्तः ।

ग्राह्याः। नेम इत्यर्धे। समः सर्वपर्यायः। तुल्यपर्यायस्तु न। समानामिति ज्ञापकात्॥ **पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्।** ।१।१।३४। एषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे। पूर्वाः। स्वाभिधेयापेक्षावधिनियमो[1] व्यवस्था। व्यवस्थायां किम्। दक्षिणा गाथकाः। कुशला इत्यर्थः। असंज्ञायां किम्। उत्तराः कुरवः॥ **स्वमज्ञातिधनाख्यायाम्** ।१।१।३५। ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे। स्वाः। आत्मीया आत्मान इति वा। ज्ञातिधनवाचिनस्तु स्वाः। ज्ञातयोऽर्था वा॥ **अन्तरं बहिर्योगोपसंव्यानयोः** ।१।१।३६। बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे अन्तरा वा गृहाः। बाह्या इत्यर्थः। अन्तरे अन्तरा वा शाटकाः। परिधानीया इत्यर्थः॥ **पूर्वादिभ्यो नवभ्यो वा** ।७।१।१६। एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्। पूर्वात्। पूर्वस्मिन्। पूर्वे। एवं परादीनामपि। शेषं सर्ववत्। (संज्ञोपसर्जनीभूतास्तु न सर्वादयः)। सर्वो नाम कश्चित्तस्मै सर्वाय देहि। अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय। (अन्तरमिति गणसूत्रेऽपुरीति वक्तव्यम्)। अन्तरायां पुरि। **तृतीयासमासे** ।१।१।३०। सर्वनामता न। मासपूर्वाय। तृतीयासमासार्थवाक्येऽपि न। मासेन पूर्वाय॥ **द्वन्द्वे च** ।१।१।३१। उक्ता संज्ञा न। वर्णाश्रमेतराणाम्॥ **विभाषा जसि** ।१।१।३२। वर्णाश्रमेतरे। वर्णाश्रमेतराः॥ **प्रथमचरमतयाल्पार्धकतिपयनेमाश्च** ।१।१।३३। एते जस्युक्तसंज्ञा वा स्युः। प्रथमे। प्रथमाः। तयप्प्रत्ययः। द्वितये। द्वितयाः। शेषं रामवत्। नेमे। नेमाः। शेषं सर्ववत्। ([2]तीयस्य ङित्सु वा)। द्वितीयस्मै। द्वितीयायेत्यादि। एवं तृतीयः। निर्जरः॥ **जराया जरसन्यतरस्याम्** ।७।२।१०१। जराया जरस् वाऽजादौ विभक्तौ। पदाङ्गाधिकारे तस्य तदन्तस्य च। निर्दिश्यमानस्यादेशा भवन्ति। एकदेशविकृतस्या-

---

१ अवधेर्नियमोऽवधिनियमः। स्वाभिधेयापेक्षश्चासाववधिनियमश्चेति विग्रहः। २ 'द्वेस्तीयः' 'त्रेः संप्रसारणं च' इति विहितस्य।

नन्यत्वाज्जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । उपजीव्यविरोधान्न जरस् । निर्जरैः । पक्षे हलादौ च रामवत् ॥ **पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु** ।६।१।६३। पाद दन्त नासिका मास हृदय निशा असृज् यूष् दोष यकृत् शकृत् उदक आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्यासन्नादेश इति काशिकायामुक्तं तत्प्रामादिकमेव । पादः । पादौ । पादाः । पादम् । पादौ । पदः, पादान् । पदा, पादेन । इत्यादि । विश्वपाः ॥ **दीर्घाज्जसि च** ।६।१।१०५। दीर्घाज्जसि इचि च न पूर्वसवर्णदीर्घः । वृद्धिः । विश्वपौ । विश्वपाः । हे विश्वपाः । हे विश्वपौ । हे विश्वपाः ॥ **सुडनपुंसकस्य** ।१।१।४३। स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥ **स्वादिष्वसर्वनामस्थाने** ।१।४।१७। कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदं स्यात् ॥ **यचि भम्** ।१।४।१८। यकारादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भं स्यात् ॥ **आकडारादेका संज्ञा** ।१।४।१। इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया या परानवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् ॥ **आतो धातोः** ।६।४।१४७। आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः । अलोऽन्त्यस्य । विश्वपः । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः ।

---

१ उपजीव्यं कारणं तद्विरोधान्न जरसादेशः । अदन्तत्वादेव भिस ऐस्प्राप्तिः पुनश्च स ऐस् यद्यजादिविभक्तित्वेनादन्तं बाधित्वा जरसादेशं प्रति निमित्तं स्यात्तदा भवेदेवोपजीव्यविरोधः । तथाच सन्निपातपरिभाषात्र प्रवर्तत एवेति ज्ञेयम् । २ अनुदात्तस्य चर्दुपधस्येत्यतोऽन्यतरस्यामित्यनुवर्तत इति भावः । ३ सुडिति प्रत्याहारस्तत एव स्वादिपञ्चानां ग्रहणम् । आगमस्य तु सुटो न ग्रहणम् । प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणमिति परिभाषणात् । सर्वनामस्थाने चेत्यत्रासंबुद्धिरिति पर्युदासाच्च । ४ एकेति स्त्रीलिङ्गात्प्रकरणाच्च संज्ञालाभे संज्ञाग्रहणं चिन्त्यप्रयोजनम् । ५ विश्वं पाति रक्षतीति विग्रहः ।

धातोः किम् । हाहान्[1] । आत इति योगविभागादधातोरप्याकारलोपः क्वचित् । क्त्वः । श्नः । हरिः । हरी ॥ **जसि च** ।७।३।१०९। ह्रस्वान्तस्याङ्गस्य गुणः । हरयः ॥ **ह्रस्वस्य गुणः** ।७।३।१०८। सम्बुद्धौ । हे हरे । हरिम् । हरीन् ॥ **शेषो घ्यसखि** ।१।४।७। शेष इति स्पष्टार्थम् । अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्ज्जं घिसंज्ञं स्यात् ॥ **आङो नाऽस्त्रियाम्** ।७।३।१२०। घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासंज्ञा प्राचाम् । हरिणा । हरिभ्याम् ३ । हरिभिः ॥ **घेर्ङिति** ।७।३।१११। घिसंज्ञकस्य ङिति सुपि गुणः । हरये । हरिभ्यः २ । गुणे कृते ॥ **ङसिङसोश्च**[3] ।६।१।११०। एङो ङसिङसोरति परे पूर्वरूपमेकादेशः । हर्योः । हरीणाम् ॥ **अच्च घेः** ।७।३।११९। इदुद्भ्यां परस्य ङेरौद्धेरत् । हरौ । हरिषु । एवं कव्यादयः ॥ **अनङ् सौ** ।७।१।९३। सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ ॥ **अलोऽन्त्यात्पूर्व उपधा** ।१।१।६५। अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥ **सर्वनामस्थाने चासम्बुद्धौ** ।६।४।८। नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने ॥ **अपृक्त एकाल्प्रत्ययः** ।१।२।४१। **हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्** ।६।१।६८। हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते ॥ **प्रत्ययलोपे प्रत्ययलक्षणम्** ।१।१।६२। प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् ॥ **नलोपः प्रातिपदिकान्तस्य** ।८।२।७। प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः । सखा ॥ **सख्युरसम्बुद्धौ**[5] ।७।१।९२। सख्युरङ्गात्परं संबुद्धिवर्ज्जं सर्वनामस्थानं णिद्वत्स्यात् ॥ **अचोऽञ्णिति** ।७।२।११५। अजन्ताङ्गस्य वृद्धिर्ञिति णिति च । सखायः । हे सखे । सखायौ ।

---

१ गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपादिकमिदम् । केचित्तु अकारो वासुदेवस्तेन सह वर्तते इति सास्तान्सानिति प्रत्युदाहरन्ति । २ क्त्वः श्नः ल्यप् श्नः क्त्वो शानज्झौ क्रमश्च क्त्वि इति निर्देशादेतत्सूत्रेष्वातो लोपः सिध्यति, तथापि क्त्वो ल्यप् भवति श्नः शानज्भवतीति व्याख्यानवाक्येष्वसाधुत्ववारणायेदमुक्तम् । ३ ङसोश्चेत्येव सिद्धे ङसिग्रहणं चिन्त्यप्रयोजनम् । ४ इदं सूत्रं त्यक्तुं शक्यम् । अपृक्तप्रदेशेषु हल्ग्रहणेनैव सिद्धेरिति केचित् । ५ सख्युरसंबुद्धिरित्येव सूत्रयितुं शक्यमिति मनोरमा ।

सखायं । सखीन् । सख्या । सखिभ्याम् । सखिभिः । सख्ये ॥ **ख्यत्यात्परस्य** ।६।१।११२। खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः । सख्युः २ ॥ **औत्** ।१।३।११८। इतरस्य ङेरौत् । सख्यौ । शेषं हरिवत् ॥ **पतिः समास एव** ।१।४।८। घिसंज्ञः । पत्या । पत्युः २ । पत्यौ । शेषं हरिवत् । समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥ **बहुगणवतुडति संख्या** । १।१।२३। **डति च** ।१।१।२२। डत्यन्ता संख्या षट्संज्ञा स्यात् ॥ **षड्भ्यो लुक्** ।७।१।२५। जश्शसोः ॥ **प्रत्ययस्य लुक्श्लुलुपः**[1] ।१।१।६१। लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ।[2] जसि चेति गुणे प्राप्ते ॥ **न लुमताङ्गस्य** ।१।१।६३। लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं[3] न स्यात् । कतिभिः । कतिभ्यः । कतिभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः[4] । त्रिभ्यः २ ॥ **त्रेस्त्रयः** ।७।१।५३। आमि । त्रयाणाम् । त्रिषु । गौणत्वेऽपि । प्रियत्रयाणाम् । द्विशब्दो नित्यं द्विवचनान्तः ॥ **त्यदादीनामः** ।७।२।१०२। एषामकारो विभक्तौ । द्विपर्यन्तानामेवेष्टिः[5] । द्वौ २ । द्वाभ्याम् ३ । द्वयोः २ । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । पाति लोकमिति पपीः—सूर्यः । पप्यौ पप्यः । हे पपीः । पपीम् । पपीन् । पप्या । पपीभ्याम् ३ । पपीभिः । पप्ये । पपीभ्यः २ । पप्यः । पप्योः । पप्याम् । पपी । पपीषु । एवं वातप्रम्यादयः । बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी ॥ **यू[6] स्त्र्याख्यौ नदी** ।१।४।३। ईदूदन्तौ

---

१ एते च विधीयमानाः सर्वादेशा एव । क्सस्याचीति प्रकृते 'लुग्वा' इति लुग्विधानात् । २ विशेषविहितापि लुगादिसंज्ञा लोपसंज्ञां न बाधते । एकसंज्ञाधिकारादन्यत्र संज्ञानां बाध्यबाधकभावानङ्गीकारादिति भावः । ३ एतच्चाङ्गमनङ्गं वेति शेखरे स्पष्टम् । ४ संख्यार्थक एव त्रिशब्दो नित्यं बहुवचनान्तो नतु शब्दवाचकः । अत एव सूत्रे त्रेरित्येव परामर्शः साधुः । ५ युष्मदस्मच्छब्दयोरिष्ट्यभावेऽपि दोषो नास्ति । आत्वयत्वलोपैर्विशेषविहितैरत्वस्य बाधनात् । ६ ईश्च ऊश्च यू व्याख्यानाद्दीर्घयोरेव ग्रहणमविभक्तिकोऽयं निर्देश इत्येके । दीर्घाज्जसि चेति निषेधस्य वा छन्दसीति पाक्षिकत्वात्प्रथमयोरिति दीर्घ इत्यन्ये ।

नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । (प्र[1]थमलिङ्गग्रहणं च) । पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥ **अम्बार्थनद्योर्ह्रस्वः** ।७।३।१०७। अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्सम्बुद्धौ । हे बहुश्रेयसि ॥ **आण् नद्याः** ।७।३।११२। नद्यन्तात्परेषां ङितामाडागमः ॥ **आटश्च** ।६।१।९०। आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । बहुश्रेयसीनाम् ॥ **ङेराम्नद्याम्नीभ्यः** ।७।३।११६। नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेरामादेशः स्यात् । इह परत्वादाटा नुट्[2] बाध्यते । बहुश्रेयस्याम् । शेषं पपीवत् । अतिलक्ष्मीः । शेषं बहुश्रयसीवत् । प्र[3]धीः ॥ **अचि श्नुधातुभ्रुवां [4]य्वोरियङुवङौ** ।६।४।७७। श्नुप्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्येतस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । इति प्राप्ते ॥ **एरनेकाचोऽसंयोगपूर्वस्य** ।६।४।८२। धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये परे । प्रध्यौ । प्रध्यः प्रध्यम् । प्रध्यः । प्रध्यि । शेषं पपीवत् । एवं ग्रामणीः । ङौ तु ग्रामण्याम् ॥ **गतिश्च** ।१।४।६०। प्रादयः क्रिया[5]योगे गतिसंज्ञाः स्युः । (गतिकारकेतरपूर्वपदस्य यण्नेष्यते) । शुद्धधियौ । शुद्धधियः ॥ **न भूसुधियोः** ।६।४।८५। एतयोरचि सुपि यण्न । सुधीः । सुधि[6]यौ । सुधियः । इत्यादि । सुखमिच्छतीति सुखीः । सुतीः । सुत्युः २ । सुख्युः २ । शेषं प्रधीवत् । शम्भुर्हरिवत् । एवं भान्वादयः ॥ **तृज्वत्क्रोष्टुः** ।७।१।९५।

---

१ इदं च यूस्त्र्या इति पूर्वसूत्रविषयमेव नतु ङिति ह्रस्वश्चेति सूत्रविषयम् । तेनातिश्रिये ब्राह्मणायेत्यत्र विकल्पो न । २ आटि कृते तु पुनर्न प्रवर्तते । सकृद्गताविति न्यायाश्रयणादिति भावः । आमि कृते नुट्प्राप्तिः स्थानिवत्त्वेन ङित्वादाड्प्राप्तिश्चेति तुल्यबलविरोधे परत्वादाड्रूपं कार्यं भवतीति भावः । ३ प्रध्यायतीति प्रधीः । ध्यायतेः संप्रसारणं चेति क्विपि संप्रसारणे पूर्वरूपे च कृते हल इति दीर्घः । यदि तु प्रकृष्टा धीर्बुद्धिर्यस्येति विगृह्यते तदा धीशब्दस्य नित्यस्त्रीत्वात् प्रथमलिङ्गग्रहणं चेति नित्यस्त्रीलिङ्गातिदेशे यथासंभवं नदीकार्यं बोध्यम् । ४ इदं च धातोर्भिन्नवचनत्वेऽपि समानाधिकरणं विशेषणम् । वेदाः प्रमाणमित्यादौ तथा दर्शनात् । ५ अयं चार्थ उपसर्गाः क्रियायोग इत्यत्र योगग्रहणाल्लभ्यते । ६ न चात्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वाल्लोपः शाकल्यस्येति यलोपः प्राप्नोतीति शङ्क्यम् । उत्तरपदत्वे चापदादिविधाविति प्रत्ययलक्षणनिषेधात् ।

असम्बुद्धौ सर्वनामस्थाने । क्रोष्टु इत्यस्य स्थाने क्रोष्टृ प्रयोक्तव्य इत्यर्थः ॥ **ऋतो ङि-सर्वनामस्थानयोः ।७।३।११०।** गुणः । इति प्राप्ते ॥ **ऋदुशनस्पुरुदंसोऽनेहसां च ।७।१।९४।** ऋदन्तानामुशनसादीनां चानङ् स्यादसम्बुद्धौ सौ ॥ **अप्तृन्-तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् ।६।४।११।** अबादीनामुपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥ **विभाषा तृतीयादिष्वचि ।७।१।९७।** अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा क्रोष्टुना । क्रोष्ट्रे । क्रोष्टवे ॥ **ऋत उत् ।६।१।१११।** ऋतो ङसिङसोरति परे पूर्वपरयोरुदेकादेशः । रपरः ॥ **रात्सस्य ।८।२।२४।** रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । विसर्गः । क्रोष्टुः २ । क्रोष्टोः २ । क्रोष्ट्वोः । (नुमचिरतृज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेन) । क्रोष्टूनाम् । क्रोष्टरि । पक्षे हलादौ च शम्भुवत् । हूहूः । हूह्वौ इत्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः २ । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥ **ओः सुपि ।६।४।८३।** धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् अचि सुपि । खलप्वौ । खलप्वः । एवं सुल्वादयः । स्वयंभूः । स्वयंभुवौ । स्वयंभुवः । एवं स्वभूः । वर्षाभूः ॥ **वर्षाभ्वश्च ।६।४।८४।** अस्य यण् स्यादचि सुपि । वर्षाभ्वावित्यादि । दृन्भूः । (दृन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः)[1] । दृन्भ्वौ । दृन्भ्वः । एवं करभूः । पुनर्भूः । दृग्भूकाराभूशब्दौ स्वयंभूवत्[2] । धाता[3] । धातारौ । धातारः । हे धातः । (ऋवर्णान्नस्य णत्वं वाच्यम्) धातॄणाम् । एवं नप्त्रादयः । अप्तृन्निति सूत्रे नप्त्रादिग्रहणं व्युत्पत्तिपक्षे[4] नियमार्थम् । तेनेह न । पिता । पितरौ । पितरः । पितरम् । शेषं धातृवत् । एवं जामात्रादयः । ना । नरौ । नरः ॥ **नृ च ।६।४।६।** अस्य नामि वा दीर्घः । नृणाम् ।

---

१ इदं च वार्तिकं वर्षाभ्वश्चेत्यत्रानुक्तसमुच्चयार्थेन चकारेण संग्राह्यमिति केचित् । २ प्राचा तु दृग्भूकाराभूशब्दौ वर्षाभूवदुदाहृतौ तदुपेक्ष्यमिति भावः । ३ दधातीति धाता अब्जयोनिः । डुधाञस्तृच् तृन् वा, अनङ्दीर्घसुलोपनलोपाः । ४ अव्युत्पत्तिपक्षे दीर्घशङ्कैव नास्ति अबादिष्वपठनादिति भावः ।

नृणाम् ॥ **गोतो णित्** ।७।१।९०। गोशब्दात्परं सर्वनामस्थानं णिद्वत् । गौः । गावौ । गावः ॥ **औतोम्शसोः** ।६।१।९३। ओकारादम्शसोरचि आकार एकादेशः । गाम् । गावौ । गाः । गवा । गवे । गोः २ ॥ **रायो हलि** ।७।२।८५। रैशब्दस्याकारादेशो हलि विभक्तौ । राः । रायौ । रायः । राभ्यामित्यादि । ग्लौः[1] । ग्लावौ । ग्लावः । ग्लौभ्यामित्यादि ॥ **इत्यजन्ताः पुंलिङ्गाः** ॥

अथाजन्तस्त्रीलिङ्गाः ।

रमा[2] ॥ **औङ आपः** ।७।१।१८। आबन्तादौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे[3] । रमाः ॥ **सम्बुद्धौ च** ।७।३।१०६। आप एकारः । हे रमे । हे रमे । हे रमाः । रमाम् । रमाः ॥ **आङि चापः** ।७।३।१०५। आङि ओसि चाप एकारः । रमया । रमाभ्याम् । रमाभिः ॥ **याडापः** ।७।३।११३। आपो ङितो याट् वृद्धिः । रमायै । रमाभ्यः । रमायाः । रमयोः । रमाणाम् । रमासु । एवं दुर्गादयः ॥ **सर्वनाम्नः स्याड्ढ्रस्वश्च**[4] ।७।३।११४। आबन्तात्सर्वनाम्नो ङितः स्याडापश्च ह्रस्वः । सर्वस्यै २ । सर्वासाम् । सर्वस्याम् । शेषं रमावत् । एवं विश्वादयोऽप्याबन्ताः ॥ **विभाषा दिक्समासे बहुव्रीहौ** ।१।१।२८। सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । इत्यादि । अन्तरस्यै शालायै । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै । तीयस्य ङित्सूपसंख्यानात् । द्वितीयस्यै । द्वितीयायै । एवं तृतीया । अम्बार्थनद्योर्ह्रस्वः । हे अम्ब । हे अक्क । हे अल्ल । असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न । हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । जरे । इत्यादि । पक्षे हलादौ च रमावत् । गोपा विश्वपावत् । मतीः । मत्या । **ङिति ह्रस्वश्च** ।१।४।६। इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इउवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति । मत्यै । मतये । मत्याः । मतेः ।

---

१ ग्लौर्मृगाङ्कः कलानिधिरित्यमराद्ग्लौश्चन्द्रः । २ रमु क्रीडायामित्यस्मात्पचाद्यचि टाप् । लिङ्गविशिष्टपरिभाषया स्वादयः । हल्ङ्यादिलोपः । ३ रमे इति । यस्येति चेति लोपस्तु न भवति अभत्वात् औङः श्यां प्रतिषेधाच्च । ४ दीर्घोच्चारणं प्राग्वत्स्पष्टप्रतिपत्त्यर्थम् ।

पत्वात् औत् इति प्राप्ते ॥ **इदुद्भ्याम्** ।७।३।११७। नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् । मत्याम् । मतौ । शेषं हरिवत् । एवं बुद्ध्यादयः ॥ **त्रिचतुरोः स्त्रियां तिसृ चतसृ** ।७।२।९९। स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ ॥ **अचि र ऋतः** ।७।२।१००। तिसृचतसृोर्ऋतो रादेशोऽचि । गुणदीर्घोत्वानामपवादः । तिस्रः २ । तिसृभिः । तिसृभ्यः । आमि नुट् ॥ **न तिसृ चतसृ** ।६।४।४। एतयोर्नामि दीर्घो न । तिसृणाम् । तिसृषु । द्वे २ । द्वाभ्याम् ३ । द्वयोः २ । गौरी । गौर्यौ । गौर्यः । हे गौरि । गौर्यावित्यादि । एवं नद्यादयः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतन्त्र्यादयः । स्त्री । हे स्त्रि ॥ **स्त्रियाः** ।६।४।७९। अस्येयङजादौ प्रत्यये । स्त्रियौ । स्त्रियः ॥ **वाऽम्शसोः** ।६।४।८०। अमि शसि च स्त्रिया इयङ् वा । स्त्रियम् । स्त्रीम् । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः २ । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रीषु । श्रीः । श्रियौ । श्रियः ॥ **नेयङुवङ्स्थानावस्त्री** ।१।४।४। इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री । हे श्रीः । श्रियै । श्रिये । श्रियाः २ । श्रियः २ ॥ **वाऽऽमि** ।२।१।५। इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री । श्रीणाम् । श्रियाम् २ । श्रियि ॥ धेनुर्मतिवत् । **स्त्रियां च** ।७।१।२६। स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥ **ऋन्नेभ्यो ङीप्** ।४।१।५। ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् । क्रोष्ट्री । गौरीवत् । वधूः । शेषं नदीवत् । भ्रूः श्रीवत् । स्वयम्भूः पुंवत् ॥ **न षट्स्वस्रादिभ्यः** ।४।१।१२। एभ्यो ङीप्टापौ न स्तः । 'स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ॥ याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥' स्वसा । स्वसारौ । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौग्लौवत् ॥ **इत्यजन्ताः स्त्रीलिङ्गाः** ॥

---

१ अत्र वार्तिकं संज्ञायां कन्युपसंख्यानमिति । तिसृकानाम ग्रामः । २ इदं च अनुवृत्त-तिसृचतसृशब्दयोः षष्ठ्यन्तत्वलाभार्थम् । ३ अत्र वा आमि इत्येव छेदः नतु अमीति । द्वितीयैकवचने नदीकार्याभावात् । ४ स्वस्रादीनां ङीप् प्राप्तः । षट्संज्ञकानां तूभावपि ।

अथाजन्तनपुंसकलिङ्गाः ।

अतोऽम् ।७।१।२४। अतोऽङ्गात्क्लीबात् स्वमोरम् । ज्ञानम् । एङ्ह्रस्वादिति सम्बुद्धिलोपः । हे ज्ञान ॥ **नपुंसकाच्च** ।७।१।१९। क्लीबादौङः शी । भसंज्ञायाम् । **यस्येति च** ।६।४।१४८। ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः । इत्यकारलोपे प्राप्ते (औङः श्यां प्रतिषेधः) ज्ञाने ॥ **जश्शसोः शिः** ।७।१।२०। क्लीबात् । **शि सर्वनामस्थानम्** ।१।१।४२। **नपुंसकस्य झलचः** ।७।१।७२। झलन्तस्याजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने ॥ **मिदचोऽन्त्यात्परः** ।१।१।४७। अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं पुंवत् । एवं धनवनफलादयः॥ **अद्ड्डतरादिभ्यः पञ्चभ्यः** ।७।१।२५। एभ्यः क्लीबेभ्यः स्वमोरद्ड्डादेशः॥ **टेः** ।६।४।१४३। डिति भस्य टेर्लोपः । कतरत् । कतरद् । कतरे । कतराणि । हे कतरत् । शेषं पुंवत् । इतरत् । अन्यत् २ । अन्यतरत् २ । अन्यतमशब्दस्य तु अन्यतममित्येव । (एकतरात्प्रतिषेधः) एकतरम् ॥ **ह्रस्वो नपुंसके प्रातिपदिकस्य** ।१।२।४७। अजन्तस्येत्येव । श्रीपं ज्ञानवत् ॥ **स्वमोर्नपुंसकात्** ।७।१।२३। लुक् । वारि ॥ **इकोऽचि विभक्तौ** ।७।१।७३। इगन्तस्य क्लीबस्य नुमचि विभक्तौ । वारिणी । वारीणि । न लुमतेत्यस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तो गुणः । हे वारे, हे वारि । घेर्ङितीति गुणे प्राप्ते । (वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन) । वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । वारीणाम् । वारिणि । हलादौ हरिवत् ॥ **तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य** ।७।१।७४। प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं

---

१ अमोऽम् विधानं स्वमोर्नपुंसकादिति प्राप्तस्य लुको बाधनार्थमेव । २ विभक्त्यपेक्षया स्त्रीलिङ्गनिर्देशः । ३ सुपीति वक्तव्ये विभक्तिग्रहणं चिन्त्यप्रयोजनम् । नामधातौ तिङि क्रियावाचकत्वेन नपुंसकत्वाभावादिति केचिदाहुः । हलादिविभक्तौ नुम्वारणार्थमेवात्राज्ग्रहणम् । स च हलादिविभक्तौ प्रवृत्तोऽपि नलोप इत्यनेन लुप्तः स्यादेवेत्यज्ग्रहणं व्यर्थं सञ्ज्ञापयति लुमताशब्देन लुप्तानामनित्यत्वमिति । ४ यद्यत्र भाषितः पुमान्येन शब्देन स भाषितपुंस्कः शब्द इति विज्ञायेत तदा पीलुने इत्यादावतिप्रसङ्गः स्यादतो व्याचष्टे—प्रवृत्तिनिमित्तैक्य इति ।

पुंवद्वा टादावचि । अनादये । अनादिने इत्यादि । शेषं वारिवत् । 'यन्निमित्तमुपादाय पुंसि शब्दः प्रवर्तते । क्लीबवृत्तौ तदेव स्यादुक्तपुंस्कं तदुच्यते ॥ पीलुर्वृक्षः फलं पीलु पीलुने नतु पीलवे । वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनः ॥' तस्मै पीलुने । न पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥ **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।७।१। ७५।** टादावचि ॥ **अल्लोपोऽनः ।६।४।१३४।** अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिप्रत्ययपरो योऽन् तस्याकारस्य लोपः । दध्ना । दध्ने । दध्नः २ । दध्नोः २ ॥ **विभाषा ङिश्योः ।६।४।१३५।** अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिप्रत्ययपरो योऽन् तस्याकारस्य लोपो वा ङिश्योः । दध्नि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षीणि । सुधि । सुधिनी । सुधीनि । हे सुधे । हे सुधि । सुधिने । इत्यादि । मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः । सुलु । सुलुनी । सुलुना । इत्यादि । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः ॥ **एच इग्घ्रस्वादेशे ।१।१।४८।** आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युना । इत्यादि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतमनन्यवत् । प्रराभ्याम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि ॥ **इत्यजन्ता नपुंसकलिङ्गाः ॥**

अथ हलन्तपुंलिङ्गाः ।

हो ढः ।८।२।३१। झलि पदान्ते च । लिट् । लिड् । लिहौ २ । लिहः । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥ **दादेर्धातोर्घः ।८।२।३२।** झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः ॥ **एकाचो बशो भष् झषन्तस्य स्ध्वोः ।८।२।३७।** धात्व-

१ एचां पूर्वभागोऽकारसदृशः उत्तरस्तु इवर्णोवर्णसदृशस्तत्रोभयान्तरतमस्य ह्रस्वस्याभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथा च मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह इगेवेति । २ डस्तु न विहितः धुट् लेढीत्याद्यसिद्ध्यापत्तेः । ३ लिट्त्स्विति ढस्य जश्त्वेन डः, तस्य खरि चेति चर्त्वेन टः । तस्यासिद्धत्वाच्चयो द्वितीया इति पक्षे टस्य ठो न । लिट्त्सु इत्यत्र तु ढस्य जश्त्वेन डकारे चर्त्वस्यासिद्धत्वात्ततः प्रागेव डः सीति पक्षे धुट् तस्य चर्त्वेन तकारः, ततो डस्य चर्त्वेन टः । ४ अत्र झषित्येव वक्तुमुचितम्, भष्पदाशक्तिकल्पनेन लाघवात् ।

वयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च । इह व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः ॥ धुक् । धुग् । दुहौ । दुहः । दुहा । धुग्भ्याम् । धुक्षु ॥ **वा द्रुहमुहष्णुहष्णिहाम्** ।८।२।३३। एषां हस्य वा घो झलि पदान्ते च । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्सु । ध्रुट्त्सु । १ । एवं मुहः ॥ **धात्वादेः षः सः** ।६।१।६४। ष्णुक् । ष्णुग् । ष्णुट् २ । एवं ष्णिहः ॥ **इग्यणः संप्रसारणम्** ।१।१।४५। यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥ **वाह ऊठ्** ।६।४।१३२। भस्य वाहः संप्रसारणमूठ् ॥ **संप्रसारणाच्च** ।६।१।१०८। संप्रसारणादचि पूर्वरूपमेकादेशः । वृद्धिः । विश्वौहः । इत्यादि ॥ **चतुरनडुहोरामुदात्तः** ।७।१।९८। सर्वनामस्थाने ॥ **सावनडुहः** ।७।१।८२। नुम् । आच्छीनद्योरिति सूत्रादादित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सुलोपः । संयोगान्तलोपः । नुम्विधिसामर्थ्याद्वसुस्रंस्विति दत्वं न । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न । अनड्वान् ॥ **अम्सम्बुद्धौ** ।७।१।९९। चतुरनडुहोः । हे अनड्वन् । अनड्वाहौ । अनडुहः ॥ **वसुस्रंसुध्वंस्वनडुहां दः** ।८।२।७२। सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । पदान्ते किम् । स्रस्तम् । ध्वस्तम् । **सहेः साडः सः** ।८।३।५६। साड्रूपस्य सहेः सस्य मूर्धन्यादेशः । तुराषाट् । तुराषाड् । तुरासाहौ । तुराषाड्भ्यामित्यादि ॥ **दिव औत्** । ७।१।८४। दिविति प्रातिपदिकस्यौत्स्यात्सौ । सुद्यौः । सुदिवौ ॥ **दिव उत्** ।६।१।८४। पदान्ते । सुद्यु-

---

१ ननु धातोरवयव इति वैयधिकरण्येनान्वये क्विबन्तस्य दुहेः दादेरिति घत्वेन झषन्तत्वेऽपि भष्भावो न स्यात् । दुघिति समुदायस्य यः पूर्वावयवो दु इत्येकाच् तस्य झषन्तत्वाभावात्, उघ्, इत्युत्तरावयवे तु बशभावादित्यत आह—व्यपदेशिवद्भावेनेति । २ एत्येधत्यूठ्स्विति विशेषणार्थष्ठकारो हलन्तमितीत्संज्ञकः । अत्र भस्येत्यधिक्रियते । वसोः संप्रसारणमित्यतोऽनुवृत्तं संप्रसारणमूठो विशेषणं तेन अलोन्त्यस्येति न भवति तदेतदाह—भस्य वाह इति । ३ एत्येधत्यूठ्स्वित्यनेन । ४ विशेषविहितेनापीत्यनुषज्यते । ५ विधानसामर्थ्यात्सर्वत्राविकृतेन नुमा भवितव्यमिति भाव इति तत्वबोधिनी ।

भ्यामित्यादि । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः २ ॥ **षट्चतुर्भ्यश्च** ।७।१।५५। एभ्य आमो नुडागमः स्यात् ॥ **रषाभ्यां नो णः समानपदे** ।८।४।१। चतुर्णाम् । **रोः सुपि**[1] ।८।३।१६। रोरेव विसर्जनीयः सुपि । चतुर्षु ॥ **मो नो धातोः** ।८।२।६४। पदान्ते । प्रशान् । प्रशामौ ॥ **किमः कः** ।७।२।१०३। विभक्तौ । कः । कौ । के । इत्यादि ॥ **इदमो मः** ।७।२।१०८। सौ । त्यदाद्यत्वापवादः ॥ **इदोऽय् पुंसि**[2] ।७।२।१११। इदम इदोऽय् सौ पुंसि । अयम् । त्यदाद्यत्वे ॥ **अतो गुणे** ।६।१।९७। अपदान्तादतो गुणे पररूपमेकादेशः ॥ **दश्च** ।७।२।१०९। इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः[3] ॥ **अनाप्यकः** ।७।२।११२। अककारस्य इदम इदोऽनापि विभक्तौ । आबिति प्रत्याहारः[4] । अनेन ॥ **हलि लोपः** ।७।२।११३। अककारस्य इदम इदो लोप आपि[5] हलादौ । (नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे) ॥ **आद्यन्तवदेकस्मिन्**[6] ।१।१।२१। एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात् । सुपि चेति दीर्घः । आभ्याम् ॥ **नेदमदसोरकोः** ।७।२।११। अककारयोरिदमदसोर्भिस ऐस् न स्यात् । एभिः । अस्मै । एभ्यः २ । अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन् । एषु ॥ **द्वितीयाटौस्स्वेनः** ।२।४।३४। इदमेतदोरन्वादेशे । किंचित्कार्यं[7] विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा अनेन व्याकरणमधीतम् । एनं

---

१ खरवसानयोरित्येव सिद्धेऽयमारम्भो नियमार्थ इत्याह—रोरेवेति । रोः सुप्येव विसर्जनीय इति विपरीतनियमस्त्वत्र न भवति । हलोऽनन्तराः संयोग इत्यादिनिर्देशात् । २ पुंसि किम् । इयं स्त्री । ३ प्रचुरप्रयोगदर्शनमेवात्र मूलम् । ४ टा इत्यारभ्य सुपः पकारेण । ५ नन्वेवं बिभर्ति पिपर्तीत्यादौ भृञामित् अर्तिपिपर्त्योश्चेतीत्वं सर्वस्याभ्यासस्य स्यात्, द्वित्वाभावे केवलस्यार्थवत्त्वेपि द्वित्वे सति समुदायस्यैवार्थवत्त्वादित्याशङ्कायामाह—अनभ्यासविकार इति । ६ सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः, सत्यन्यस्मिन् यस्य परो नास्ति सोऽन्त इति लोके प्रसिद्धम् । तदुभयमेकस्मिन्नसंहाये न संभवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि न स्युरतोऽयमतिदेश आरभ्यते । ७ किंचित्कार्यमिति । अपूर्वं बोधयितुमित्यर्थः । ईषदर्थे क्रियायोग इत्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यन्त इति न तत्रैनादेशः । एतेन नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय इत्यपि व्याख्यातम् ।

छन्दोऽध्यापयेति । अनयोः पवित्रं कुलम् । एनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः २ । राजा ॥ **न ङिसम्बुद्ध्योः** ।८।२।८। नस्य लोपो न ङौ सम्बुद्धौ च । हे राजन् । (ङावुत्तरपदे प्रतिषेधः) ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । जस्योर्ज्ञः । राज्ञः ॥ **नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति** ।८।२।२। सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजाश्व[1] इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राजभ्यः । राज्ञि । राजनि । यज्वा । यज्वानौ । यज्वानः ॥ **न संयोगाद्वमन्तात्** ।६।४।१३७। वमान्तसंयोगादनोऽकारस्य लोपो न । यज्वनः । यज्वना । यज्वभ्याम् । ब्रह्मणः ॥ **इन्हन्पूषार्यम्णां शौ**[2] ।६।४।१२। एषां शावेवोपधाया दीर्घः ॥ **सौ च** ।६।४।१३। इन्नादीनामुपधाया दीर्घोऽसम्बुद्धौ सौ । वृत्रहा । हे वृत्रहन् ॥ **एकाजुत्तरपदे णः** ।८।४।१८। एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य णत्वं स्यात् । वृत्रहणौ । वृत्रहणः ॥ **हो हन्तेर्ञ्णिन्नेषु** ।८।३।२२। ञिति णिति प्रत्यये ने च परे हन्तेर्हस्य कुत्वं स्यात् ॥ **हन्तेः** ।८।४।१२। उपसर्गस्थान्निमित्ताद्धन्तेर्नस्य णः । प्रहण्यात् ॥ **अत्पूर्वस्य** ।८।४।२२। हन्तेरत्पूर्वस्यैव नस्य णो नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यादनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायं बाधित्वा कुमतिचेति णोपि निवर्तते । वृत्रघ्नः इत्यादि । एवं शार्ङ्गिन् । यशस्विन् । अर्यमन् । पूषन् ॥ **मघवा बहुलम्**[3] ।६।४।१२८। मघवन्शब्दस्य वा तृ इत्यन्तादेशः । ऋ इत् ॥ **उगिदचां सर्वनामस्थानेऽधातोः**[4] ।७।१।७०। अधातोरुगितो नलोपि-

---

१ राजाश्व इत्यादौ सवर्णदीर्घे कर्तव्ये नलोपोऽसिद्धो न भवतीति भावः । २ 'सर्वनामस्थाने चासंबुद्धौ' इत्यनेनैव सिद्धे नियमार्थमिदमित्याह—शावेवेति । उपधादीर्घमात्रस्यायं नियमः । तेन वृत्रहायत इत्यत्र अकृत्सार्वधातुकयोरिति दीर्घो भवत्येव । ३ अर्वणस्त्रसावित्यतस्तृ इत्यनुवर्तते ।-तदपेक्षा च मघवा इति षष्ठ्यर्थे प्रथमा, तदाह मघवन्शब्दस्येति । ४ अधातोरिति अधातुभूतपूर्वस्यापीत्यर्थः । अञ्चतिग्रहणं तु नियमार्थम् । उगितो धातोश्चेद्भवति तर्ह्यञ्चतेरेवेति । एवं च गोमानिवाचरतीति गोमान् इत्यादौ संप्रति धातुत्वेपि नुम् भवत्येव ।

नोऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने । मघवान् । इह उपधादीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति । बहुल[1]ग्रहणात् । मघवन्तौ । मघवतः । मघवता । तृत्वाभावे सुटि राजवत् ॥ **श्वयुवमघोनामतद्धिते** ।६।४।१३३। अन्नन्तानामेषामतद्धिते परे संप्रसारणं स्यात् । मघोनः । मघवभ्यामित्यादि । एवं श्वन् युवन् ॥ **न संप्रसारणे संप्रसारणम्** ।६।१।३७। यूनः । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥ **अर्वणस्त्रसावनञः** ।६।४।१२७। नञा रहितस्यार्वन्नित्यस्य तृ इत्यन्तादेशो न तु सौ । अर्वन्तौ । अर्वतः । अर्वद्भ्याम् ॥ **पथिमथ्यृभुक्षामात्** ।७।१।८५। सौ ॥ **इतोऽत्सर्वनामस्थाने** ।७।१।८६। पथ्यादेः ॥ **थो[2] न्थः** ।७।१।८७। पथि[3]मथोस्थस्य न्थादेशः सर्वनामस्थाने । पन्थाः । हे पन्थाः । पन्थानौ । पन्थानः ॥ **भस्य टेर्लोपः** ।७।१।८८। पथ्यादेः । पथः । पथिभ्याम् । पथिभ्यः । एवं मन्थाः । ऋभुक्षाः ॥ **[4]ष्णान्ता षट्** ।१।१।२४। षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । पञ्च २ । पञ्चभिः । षट्चतुर्भ्यश्चेति नुट् ॥ **नोप[5]धायाः** ।६।४।७। नान्तस्योपधाया दीर्घो नामि । पञ्चानाम् । पञ्चसु ॥ **अष्टन आ विभक्तौ** ।७।२।८४। हलादौ वा[6] स्यात् ॥ **[7]अष्टाभ्य औश्** ।७।१।२१। कृताकारादष्टनो जश्शसोरौश् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । अष्टौ २ । अष्टाभिः । अष्टाभ्यः २ । अष्टानाम् । अष्टासु । आत्वाभावे अष्ट । पञ्चवत् ॥ **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च** ।३।२।५९। एभ्यः क्विन् । अञ्चेः सुप्युपपदे । युजिक्रुञ्चोः केवलयोः । क्रुञ्चेर्नलोपाभावश्च निपात्यते । कनावितौ ।

---

१ क्वचिदन्यदेवेत्यर्थकादित्यर्थः । बहूनर्थान् लातीति बहुलम् । २ यो नुडिति नोक्तं इत्संज्ञाद्यन्तावित्यनुसंधानेन प्रक्रियालाघवाभावात् । ३ स्थान्यादेशौ द्वावप्यनच्कौ । थेन्थः इत्येव सिद्धे इतोऽत्सर्वनामस्थाने इत्येतदृभुक्षिन्नर्थम् । ४ स्त्रीलिङ्गनिर्देशः संख्यां विशेषयितुम् । ५ नेति लुप्तषष्ठीकमङ्गस्य विशेषणम् । नलोपस्यासिद्धत्वात् नामीति दीर्घो न प्रवर्तते इत्ययमारम्भः । ६ वैकल्पिकं चेदमात्वम् । अष्टनो दीर्घादिति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । ७ अष्टाभ्य इति कृतात्वस्येदमनुकरणं न तु लक्षणवशसंपन्नमात्वं, तथाहि सति तु वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थं अष्टभ्य इत्येव ब्रूयादिति भावः ।

कृदतिङ् ।३।१।९३। अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः ॥ **वेरपृक्तस्य** ।६।१।६७। लोपः॥ **क्विन्प्रत्ययस्य कुः** ।८।२।६२। क्विन्प्रत्ययो यस्मात्तस्य[1] कवर्गोऽन्तादेशः पदान्ते । ऋत्विक् । ऋत्विग् । ऋत्विग्भ्याम् ॥ **युजेरसमासे** ।७।१।७१। सर्वनामस्थाने नुम् । सुलोपः । संयोगान्तस्य लोपः । कुत्वेन नस्य ङः । युङ् । युञ्जौ । युञ्जः । युग्भ्याम् । असमासे किम् । सुयुग्[2] ॥ **चोः कुः** ।८।२।३०। चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । सुयुक् । सुयुजौ । सुयुजः । सुयुग्भ्याम् । खन् । खञ्जौ । खञ्जः । खन्भ्याम् ॥ **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** ।८।२।३६। झलि पदान्ते च । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राड्भ्याम् । एवम् । विभ्राट् । देवेट् । विश्वसृट् । परिमृट् ॥ **'परौ व्रजेः षः पदान्ते'** । परावुपपदे व्रजेः क्विप् दीर्घश्च पदान्ते षत्वमपि । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ ॥ **विश्वस्य वसुराटोः**[3] ।६।३।१२८। विश्वस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । राडिति पदान्तोपलक्षणार्थम् । विश्वाराट् । विश्वराजौ । विश्वाराड्भ्याम् ॥ **स्कोः संयोगाद्योरन्ते च** ।८।२।२९। पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः । भृट् । सस्य श्चुत्वेन शः । झलां जश्झशीति शस्य जः । भृज्जौ । भृज्जः । भृड्भ्याम् । त्यदाद्यत्वं पररूपत्वम् ॥ **तदोः सः सावनन्त्ययोः** ।७।२।१०६। त्यदादीनां तकारदकारयोः सः स्यात्सौ । स्यः । त्यौ । त्ये । सः । तौ । ते । यः । यौ । ये । एषः । एतौ । एते । एनम् । एनौ । एनान् । एनेन । एनयोः ॥ **ङेप्रथमयोरम्** ।७।१।२८। युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः ॥ **त्वाहौ सौ** ।७।२।९४। अनयोर्मपर्यन्तस्य ॥ **शेषे[4] लोपः** ।७।२।९०। अनयोष्टिलोपः । त्वम् । अहम् ॥ **युवावौ द्विवचने** ।७।२।९२। द्वयो-

---

१ क्विनः कुः इत्युक्तेऽपि प्रत्ययग्रहणे तदन्तग्रहणात् क्विन्नन्तस्य ग्रहणे सिद्धे प्रत्ययग्रहणं बहुव्रीहिविज्ञानार्थमित्याशयेन व्याचष्टे—क्विन्प्रत्ययो यस्मादिति ॥ २ सुष्ठु युनक्तीनि विग्रहे सत्सूद्विषेति क्विप्। ३ रट्धातोर्णिचि क्विपि निष्पन्नराट्शब्दस्य तु नेह ग्रहणम् । सुप्रसिद्धत्वेन वसुशब्दसाहचर्येण चैश्वर्यसंबन्ध्यर्थप्रतिपादकस्य राजतिनिष्पन्नस्यैव ग्रहणात् । आदित्यविश्ववसव इत्यत्र तु विश्वशब्दस्य पूर्वपदत्वाभावान्न दीर्घः। ४ उक्तादन्यः शेषः, आत्वं यत्वं च प्रागुक्तं, तद्विषयादन्यविभक्तिः शेषशब्दार्थः ।

रुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥ **प्रथमायाश्च द्विवचने भाषायाम्** ।७।२।८८। औङ्येतयोरात्वं लोके । युवाम् । आवाम् ॥ **यूयवयौ जसि** ।७।२।९३। अनयोर्मपर्यन्तस्य । यूयम् । वयम् ॥ **त्वमावेकवचने**[1] ।७।२।९०। एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥ **द्वितीयायां च** ।७।२।८७। अनयोरात्स्यात् । त्वाम् । माम् ॥ **शसो न** ।७।१।२९। आभ्यां शसो नः । अमोपवादः । 'आदेः परस्य' । संयोगान्तलोपः । युष्मान् । अस्मान् ॥ **योऽचि** ।७।२।८९। अनयोर्यादेशोऽनादेशेऽजादौ विभक्तौ । त्वया । मया ॥ **युष्मदस्मदोरनादेशे** ।७।२।८३। अनयोरात्स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥ **तुभ्यमह्यौ ङयि** ।७।२।९५। अनयोर्मपर्यन्तस्य । टिलोपः । तुभ्यम् । मह्यम् ॥ **भ्यसोऽभ्यम्** ।७।१।३०। आभ्यां परस्य । युष्मभ्यम् । अस्मभ्यम् ॥ **एकवचनस्य च** । ७।१।३२। आभ्यां ङसेरत् । त्वत् । मत् ॥ **पञ्चम्या अत्** ।७।१।३१। आभ्यां भ्यसः । युष्मत् । अस्मत् ॥ **तवममौ ङसि** ।८।१।९६। अनयोर्मपर्यन्तस्य ॥ **युष्मदस्मद्भ्यां ङसोऽश्**[2] ।७।२।९६। तव । मम । युवयोः २ । आवयोः २ ॥ **साम आकम्** ।७।२।३३। आभ्यां साम आकम् । युष्माकम् । अस्माकम् । त्वयि । मयि । युष्मासु । अस्मासु ॥ **युष्मदस्मदोः**[3] **षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ** ।८।१।२०। पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वान्नावौ ॥ **बहुवचनस्य वस्नसौ** ।८।१।२१। उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः ॥ **तेमयावेकवचनस्य** ।८।१।२२। उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥ **त्वामौ द्वितीयायाः** ।८।१।२३। उक्तविधयोर्द्वितीयैकवचनान्तयोस्त्वामौ स्तः ॥

---

१ अत्रापि विभक्ताविति संबध्यते । अतएव प्रत्ययोत्तरेति सूत्रं सार्थकम् । तत्फलं तु त्वं सुन्दरः पुत्रो यस्येति त्रिपदे बहुव्रीहौ नादेश इति । २ शित्वं सर्वादेशार्थं । अन्यथा आदेः परस्येति स्यात् । ३ एतत्पूर्वं पदस्य, पदात्, अनुदात्तं सर्वमपादादौ, इत्येतत्सूत्रत्रयाधिकारः ।

श्रीश[1]स्त्वाऽवतु माऽपीह दत्तात्ते मेऽपि शर्म सः ।
स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ १ ॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ २ ॥

(एक[2]वाक्ये, निघातयुष्मदस्मदादेशा वक्तव्याः) । एकतिङ् वाक्यम् । तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामि । (एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः । अन्वादेशे तु नित्यं स्युः) । धाता ते भक्तोऽस्ति । तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥ **न चवाहाहैव युक्ते** ।८।१।२४। चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि ॥ **पश्यार्थैश्चानालोचने** ।८।१।२५। अचाक्षुषज्ञानार्थैर्धातुभिर्योगे नैते आदेशाः स्युः । चेतसा त्वां समीक्षते । आलोचने तु भक्तस्त्वा पश्यति चक्षुषा ॥ **[3]सपूर्वायाः प्रथमाया विभाषा** ।८।१।२६। विद्यमानपूर्वात्प्रथमान्तादन्वादेशेऽप्येते आदेशा वा स्युः । भ[4]क्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वामेति वा ॥ **[5]सामन्त्रितम्** ।२।३।४८। सम्बोधने या प्रथमा तदन्तमामन्त्रितसंज्ञं स्यात् ॥ **आमन्त्रितं पूर्वमविद्यमानवत्** ।८।१।७२। अग्ने तव । देवास्मान्पाहि ॥ **नामन्त्रिते समानाधिकरणे सामान्यवचनम्** ।८।१।७३। विशेष्यं समानाधिकरणे विशेषणे आमन्त्रिते परे नाविद्यमानवत् । हरे दयालो नः पाहि । सुपात् । सुपाद् । सुपादौ ॥ **पादः पत्** ।६।४।१३०। पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः । सु-

---

१ अस्मिन्पद्यद्वयेऽनुक्रमेण द्वितीयाचतुर्थीषष्ठीनामेकवचनस्य तत आसामेव द्विवचनस्य ततो बहुवचनस्योदाहरणानीति ज्ञेयम् । २ सिद्धान्तकौमुद्यां तु समानवाक्ये इत्यस्ति तदर्थ एवात्र एकवाक्ये इति पठितोऽस्ति । ३ सहशब्दोऽत्र सलोमक इत्यत्रेव विद्यमानवचनः । तेन सहेतीत्यत्र तुल्ययोगवचनं प्रायिकमिति वक्ष्यमाणत्वाद्विद्यमानवचनस्यापि सहस्य समासः । वोपसर्जनस्येति सभावः । ४ त्वं भक्तोऽहमिति तेन हरिस्त्वां मां च त्रायत इति संबन्धः । ५ सा इत्यनेन प्रथमा निर्दिश्यते ।

पदः । सुपाद्भ्याम् । अग्निमत् । अग्निमद् । अग्निमथौ । अग्निमद्भ्याम् ॥ **अनिदितां हल उपधायाः क्ङिति** ।६।४।२। हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति च । उगिदचामिति नुम् । संयोगान्तस्य लोपः । नस्य कुत्वेन ङः । प्राङ् । प्राञ्चौ । प्राञ्चः ॥ **अचः**[1] ।६।४।१३८। लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः ॥ **चौ** ।६।३।१३८। लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः । प्राचः । प्राचा । प्राग्भ्याम् । प्रत्यङ् । प्रत्यञ्चौ । प्रतीचः । प्रत्यग्भ्याम् । उदङ् । उदञ्चौ ॥ **उद ईत्** ।६।४।१२९। उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत् । उदीचः । उदीचा । उदग्भ्याम् ॥ **समः**[2] **समि** ।६।३।९६। अप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । समीचः । सम्यग्भ्याम् ॥ **सहस्य सध्रिः** ।६।३।९५। तथा । सध्र्यङ् । सध्र्यञ्चौ । सध्रीचः । सध्र्यग्भ्याम् ॥ **तिरसस्तिर्यलोपे** ।६।३।९४। अलुप्ताकारेऽञ्चतौ अप्रत्ययान्ते तिरसस्तिर्यादेशः । तिर्यङ् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्याम् ॥ **नाञ्चेः पूजायाम्** ।६।४।३०। पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न । प्राङ् । प्राञ्चौ । नलोपाभावादलोपो न । प्राञ्चः । प्राङ्भ्याम् । प्राङ्षु । प्राङ्क्षु । एवं पूजार्थे प्रत्यङ्ङादयः । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्याम् । पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । पयोमुग्भ्याम् । मह पूजायाम् । 'वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च' एते निपात्यन्ते[3] । शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् ॥ **सान्तमहतः संयोगस्य** ।६।४।१०। सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने । महान् । महान्तौ । महान्तः । हे महन् । महतः । महद्भ्याम् ॥ **अत्वसन्तस्य चाधातोः**[4] ।६।४।१४। अत्वन्तस्योपधाया

---

१ अत्र अजिति न प्रत्याहारः आतो धातोरित्यारम्भात्, प्रतीचो यदिति निर्देशाच्च । अतएव पचाद्यचो न ग्रहणम् । २ समो मिङ्, सम इक् इति च नासूत्रि । परिभाषाज्ञानगौरवपरिहारार्थत्वात् । ३ निपात्यन्त इति । पृषु सेचने, मह पूजायाम्, बृह वृद्धौ अत्र गुणाभावः । महेः कर्मणि प्रत्ययः । अत एव महानित्यत्र मह्यते पूज्यते स महानिति विग्रहः । बृहेर्वृद्ध्यभावः । गमेस्तु जगादेशश्च चत्वारोऽप्यतिप्रत्ययान्ताः । ४ अधातोरिति योगो विभज्यते, तत्सामर्थ्यादनन्तरस्यासन्तस्यैव प्रतिषेधः नत्वत्वन्तस्येति तदेतद्दर्शयति धातुभिन्नासन्तस्य चेति ।

दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । भातेर्डवतुः । डित्वसामर्थ्याद्भस्यापि टेर्लोपः । भवान् । भवन्तौ । शत्रन्तस्य तु भवन् ॥ **उभे अभ्यस्तम्** ।६।१।५। षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे[1] समुदिते अभ्यस्तसंज्ञे स्तः ॥ **नाभ्यस्ताच्छतुः** ।७।१।७८। नुम् न । ददत् । ददतौ ॥ **जक्षित्यादयः**[2] **षट्** ।६।१।६। षट् धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीङ् दीप्तिदेवनयोः । वेवीङ् वेतिना तुल्ये । एतौ छान्दसौ । दीध्यत् । वेव्यत् ॥

जक्षि जागृ दरिद्रा शास् दीधीङ् वेवीङ् चकास्तथा ।
अभ्यस्तसंज्ञा विज्ञेया धातवो मुनिभाषिताः ॥ १ ॥

गुप् । गुब् । गुपौ । गुपः । गुब्भ्याम् ॥ **त्यदादिषु दृशोऽनालोचने कञ्च** ।३।२।६०। त्यदादिषूपपदेषु अज्ञानार्थाद्दृशेर्धातोः कञ् स्यात् चात्क्विन् ॥ **आ सर्वनाम्नः** ।६।३।९१। दृग्दृश्वतुषु । तादृक् । तादृग् । तादृशौ । तादृशः । तादृग्भ्याम् । व्रश्चेति षः । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विड्भ्याम् ॥ **नशेर्वा**[3] ।८।२।६३। नशेः कवर्गोऽन्तादेशो वा पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नड्भ्याम् । नग्भ्याम् ॥ **स्पृशोऽनुदके क्विन्** ।३।२।५८। अनुदके सुप्युपपदे स्पृशेः क्विन् । घृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्याम् । रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः । रत्नमुड्भ्याम् । षट् । षड् । षड्भिः । षड्भ्यः । षण्णाम् । षट्त्सु । षट्सु । यत्तु प्राचा षण्णां षैड्णामित्युदाहृतं तत्प्रामादि-

---

१ द्वे इत्यनुवृत्त्यैव सिद्धे उभेग्रहणं समुदायप्रतिपत्त्यर्थमिति व्याचष्टे । उभे समुदिते इति ।
२ जक्ष् इति पृथक्पदम् । इतिशब्देन जक्षिरेव परामृश्यते इति आदिर्येषामित्यतद्गुणसंविज्ञानो बहुव्रीहिस्तदेतदाह––षड्धातवोऽन्ये जक्षितिश्च सप्तम इति । ३ केचिदिह झलीत्यनुवर्त्य झलि पदान्ते चेति व्याचक्षते । तन्न नष्टमित्यादावतिप्रसङ्गात् । ४ अत्र यरोऽनुनासिकेऽनुनासिको वा इति विकल्पं बाधित्वा प्रत्यये भाषायां नित्यमिति वचनान्नित्यमनुनासिकः ॥

कमेव । प्रत्यये नित्यवचनात् ॥ **र्वोरुपधाया दीर्घ इकः** ।८।२।७६। रेफवान्तस्य धातोरुपधाया इको दीर्घः पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् ॥ **नुम्विसर्जनीयशर्व्यवायेऽपि** ।८।३।५८। एतैः प्रत्येकं व्यवधानेऽपीण्कुभ्यां परस्य सस्य मूर्धन्यादेशः । ष्टुत्वेन पूर्वस्य षः । पिपठीष्षु । पिपठीःषु । चिकीः । चिकीर्षौ । चिकीर्षु । विद्वान् । विद्वांसौ । हे विद्वन् ॥ **वसोः संप्रसारणम्** ।६।४।१३१। वस्वन्तस्य भस्य संप्रसारणम् । विदुषः । वसुस्रंस्विति दत्वम् । विद्वद्भ्याम् ॥ **पुंसोऽसुङ्** ।७।१।८९। सर्वनामस्थाने । पुमान् । हे पुमन् । पुमांसौ । पुंसः । पुंभ्याम् । पुंसु । ऋदुशनेत्यनङ् । उशना[1] । उशनसौ । (अस्य सम्बुद्धौ वाऽनङ् नलोपश्च वा वाच्यः) हे उशन । उशनन् । हे उशनः । उशनोभ्याम् । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । वेधाः । वेधसौ । वेधसः । वेधोभ्याम् ॥ **अदस औ सुलोपश्च** ।७।२।१०७। सौ परे । तदोरिति सः । असौ ॥ **औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च** । असकौ । असुकः[3] । त्यदाद्यत्वं पररूपत्वम् । वृद्धिः ॥ **अदसोसेर्दादु दो मः** ।८।२।८०। अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च । आन्तरतम्याद्ध्रस्वस्य उः । दीर्घस्य ऊः । अमू । जसः शी ॥ **एत ईद्बहुवचने** ।८।२।८१। अदसो दात् परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥ **न[4] मु ने** ।८।२।३। नाभावे कर्तव्ये कृते च मुभावो नासिद्धः । अमुना । अमूभ्याम् । अमीभिः । अमुष्मै । अमीभ्यः । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ॥ इति हलन्ताः पुंलिङ्गाः ॥

---

१ असंबुद्धावित्युक्तेः सान्त इति न दीर्घः । २ वशेः कनसिः, ग्रहिज्येति संप्रसारणम् । ३ औत्वाभावे त्यदाद्यत्वं सादुत्वम् । ४ ने इति विषयसप्तमीत्याह—नाभावे कर्तव्य इति । अन्यथा घेः परत्वाभावान्नाभावो न स्यादिति भावः । नन्वेवमपि कृते नाभावे सुपि चेति दीर्घः स्याद् दीर्घं प्रति मुत्वस्यासिद्धत्वादत आह—कृते चेति । एतच्च ने इत्यस्यावृत्त्या लभ्यते । एकत्र विषयसप्तम्यपरत्र तु सतिसप्तमीत्याश्रयणात् ॥

अथ हलन्ताः स्त्रीलिङ्गाः ।

नहो धः ।८।२।३४। झलि पदान्ते च ॥ **नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।६।३।११६।** क्विबन्तेष्वेषु[1] पूर्वस्याणो दीर्घः । उपानत्[2] । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिग्भ्याम् । द्यौः । दिवौ । दिवः । द्युभ्याम् । गीः । गिरौः । गिरः । एवं पूः । चतस्रः । चतसृभिः । चतसृभ्यः । चतसृणाम्[3] । चतसृषु । का । के । काः । सर्वावत् ॥ **यः सौ ।७।२।११०।** इदमो दस्य । 'इदमो मः' । इयम् । त्यदाद्यत्वम् । टाप् । दश्चेति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया । हलि लोपः । आभ्याम् । आभिः । अस्यै । अस्याः २ । अनयोः २ । आसाम् । अस्याम् । आसु । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । त्यदाद्यत्वे टाप् । स्या । त्ये । त्याः । एवम् । तद् । यद् । एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् ३ । अप्शब्दो नित्यं बहुवचनान्तः । अप्तृन्निति दीर्घः । आपः । अपः ॥ **अपो भि ।७।४।४८।** अपस्तकारो भादौ प्रत्यये । अद्भिः । अद्भ्यः । अपाम् । अप्सु । दिक् । दिशौ । दिशः । दिग्भ्याम् । त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृशौ । दृशः । दृग्भ्याम् । त्विट् । त्विषौ । त्विषः । त्विड्भ्याम् । ससजुषोरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् । आशीः[4] । आशिषौ । आशीर्भ्याम् । असौ । उत्वमत्वे । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्यः । अमुष्याः २ । अमुयोः २ । अमूषाम् । अमुष्याम् । अमूषु । इति हलन्ताः स्त्रीलिङ्गाः ॥

अथ हलन्तनपुंसकलिङ्गाः ।

स्वमोर्लुक् । दत्वम्[5] । स्वनडुत् । स्वनडुही । चतुरनडुहोरित्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् । वाः । वारी । वारि । वारा । वार्भ्याम् । चत्वारि । किम् ।

---

१ उत्तरपदेष्विति शेषः । २ उपपूर्वान्नहेः संपदादित्वात्क्विप् । नहिवृतीति पूर्वपदस्य दीर्घः । ३ न तिसृचतसृ इति न दीर्घः । ४ आशासः क्वावुपसंख्यानमित्युपधाया इत्वम् । ५ वसुस्रंस्विति दत्वमनडुच्छब्दान्तेऽपि प्रवर्तते; पदाधिकारस्थत्वादिति भावः ।

के । कानि । इदम् । इमे । इमानि । (अन्वादेशे नपुंसके एनद्वक्तव्यः) । एनत् । एने । एनानि । एनेन । एनयोः २ । व्योम । व्योम्नी । व्योमनी । व्योमानि । ब्रह्म । (संबुद्धौ नपुंसकानां नलोपो वा वाच्यः) । हे ब्रह्म । हे ब्रह्मन् । हे ब्रह्मणी । हे ब्रह्माणि । 'रोऽसुपि' । अहः । 'विभाषा ङिश्योः' । अह्नी । अहनी । अहानि ॥ **अहन्** ।८।२।६८। अहन्नित्यस्य रुः पदान्ते । अहोभ्याम् । दण्डि[1] दण्डिनी । दण्डीनि । सुपथि । टिलोपः । सुपथी । सुपन्थानि । ऊर्क् । ऊर्जी । ऊर्न्जि । नरजानां संयोगः । त्यद् । त्ये । त्यानि । तत् । ते । तानि । यत् । ये । यानि । एतत् । एते । एतानि । अवङ् स्फोटायनस्येति अवङ् ।

गवाक्शब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः ।
असंध्यवङ्पूर्वरूपैर्नवाधिकशतं मतम् ॥ १ ॥
स्वमुसुप्सु नव षट् भादौ षट्के स्युस्त्रीणि जश्शसोः ।
चत्वारि शेषे दशके रूपाणीति विभावय ॥ २ ॥

गवाक् । गवाग् । गोची । गवाञ्चि । पुनस्तद्वत् । गोचा । गवाग्भ्याम् । शकृत् । शकृती । शकृन्ति । ददत् । ददती ॥ **वा नपुंसकस्य** ।७।१।७९। अभ्यस्तात्परो यः शतुरवयवस्तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने । ददति । ददन्ति । तुदत् ॥ **आच्छीनद्योर्नुम्** ।७।१।८०। अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्य नुम्वा शीनद्योः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥ **शप्श्यनोर्नित्यम्** ।७।१।८१। शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नुम् शीनद्योः । पचन्ती । दीव्यत् । दीव्यन्ती । धनुः । धनुषी । सान्तेति दीर्घः । नुम्विसर्जनीयेति षः । धनूंषि । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पयः । पयसी । पयांसि । पयोभ्याम् । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥ इति हलन्ता नपुंसकलिङ्गाः ॥

---

१ अम्येवेदं विधीयते नत्वौट्शसादिषु फलाभावात् । २ पूजार्थगत्यर्थभेदेनासंध्यवङादिभिर्नवाधिकशतं रूपाणि बोध्यानीत्यर्थः । ३ इह 'चयो द्वितीया' इति वार्तिकमनाश्रित्य नवाधिकशतं बोध्यम् । तदाश्रयणे तु त्रीणि रूपाणि वर्धन्त एव ।

अथाव्ययानि।

स्वरादिनिपातमव्ययम् ।७।१।३७। स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । वत् । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । तिरस् । उपधा । अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना । स्वस्ति । स्वाहा । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम् । प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रतान् । प्रशान् । मा । माङ् । आकृतिगणोयम् । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । चण् । यत्र । कच्चित् । नह । हन्त । माकिम् । माकीम् । माकिः । नकिम् । नकिः । आकीम् । माङ् । नञ् । यावत् । तावत् । त्वै । द्वै । न्वै । रै । श्रौषट् । वौषट् । स्वाहा । स्वधा । अलम् । वषट् । तुम् । तथाहि । खलु । किल । अथ । सुष्ठु । स्म । आदह । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । अवदत्तम् । अहंयुः । अस्तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथा । कथाच । पाट् । प्याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु । एकपदे ।

---

१ स्वरादयश्च निपाताश्चेति समाहारद्वन्द्वः । २ तेनान्येऽपि ज्ञेयाः । तथाहि कामम् । प्रकामम् । भूयः । सांप्रतम् । परम् । साक्षात् । साचि । सत्यम् । मङ्क्षु । आशु । संवत् । अवश्यम् । उषा । ओम् । भूः । भुवः । झटिति । झगिति । तरसा । सुष्ठु । दुष्ठु । सु । अदस् । कु । अञ्जसा । मिथु । अस्तम् । स्थाने । वरम् । सुदि । वदि । इत्यादि । ३ एतेषामनेकाचामुभयत्र पाठः स्वरभेदार्थः ।

पत् । आतः । चादिरप्याकृतिगणः ॥ **तद्धितश्चासर्वविभक्तिः** ।१।१।३८। यस्मात्सर्वा विभक्तिर्नोत्पद्यते[1] स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञौ । इति । एतदन्तमव्ययम् । अत इत्यादि ॥ **कृन्मेजन्तः**[2] ।१।१।३९। कृद्यो मान्त एजन्तश्च तदन्तमव्ययम् । स्मारंस्मारम्[3] । जीवसे[4] । पिबध्यै । **क्त्वातोसुन्कसुनः** ।१।१।४०। एतदन्तमव्ययम् । कृत्वा[5] । उदेतोः । विसृपः ॥ **अव्ययीभावश्च** ।१।१।४१। अधिहरि ॥ **अव्ययादाप्सुपः** ।२।४।८२। अव्ययाद्विहितस्यापः सुपश्च लुक् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे । आप्ग्रहणं व्यर्थम् । अव्ययस्यालिङ्गत्वात् । तथा च श्रुतिः ।

सदृशं[6] त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ १ ॥
वष्टि[7] भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ २ ॥

अवगाहः । वगाहः । अपिधानम् । पिधानम् ॥ इत्यव्ययानि ॥

इति सुबन्तं समाप्तम् ॥ ॥

---

१ किंत्वेकवचनमेवोत्पद्यत इति भावः । २ अत्र मेजन्त इत्येतच्छ्रुतत्वात्कृत एव विशेषणं नतु कृदन्तस्याश्रुतस्य । ३ स्मरतेः आभीक्ष्ण्ये णमुल् च इति णमुल् । वृद्धिः रपरत्वम् । नित्यवीप्सयोरिति द्वित्वम् । ४ तुमर्थे सेसेनित्यसेप्रत्ययः । पिबध्यै इति तुमर्थ इत्यनेनैव शध्यै प्रत्ययः । पाघ्रा इति पिबादेशः । ५ कृत्वेति समानकर्तृकयोः इत्यादिना क्त्वा । उदेतोरिति उत्पूर्वादिणो भावलक्षणेस्थेण् इत्यादिना तोसुन् । विसृप इति सृपितृदोः कसुन् । ६ अलिङ्गत्वे अथर्वणप्रणवविद्यागतश्रुतिविरोधमाशङ्क्याह—सदृशमिति । एतेषु यन्न व्येति किंतु सदृशमेकप्रकारं तदव्ययमिति योजना । यद्वा यस्मान्न व्येति तदव्ययम् । ७ अव्ययविशेषे कार्यान्तरमाह—वष्टीति । भागुरिराचार्यः अव उपसर्गस्य अपि उपसर्गस्य च पूर्वाकारस्य लोपमिच्छति तथा वाक् निश् दिशादिहलन्तशब्दानामापमिच्छति ।

तिङन्तं प्रारभ्यते ।

तिङन्ते भ्वादयः ।

श्रीः ॥ लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लृङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥ **लः कर्मणि च भावे चाकर्मकेभ्यः** ।३।४।६९। लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥ **वर्तमाने लट्** ।३।२।१२३। वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ । उच्चारणसामर्थ्याल्लस्य नेत्वम् । भू सत्तायाम् । कर्तृविवक्षायाम् भू ल् इति स्थिते ॥ **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** ।३।४।७८। एतेऽष्टादश लादेशाः स्युः ॥ **लः परस्मैपदम्** ।१।४।९९। लादेशाः परस्मैपदसंज्ञाः स्युः ॥ **तङानावात्मनेपदम्** ।१।४।१००। तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥ **अनुदात्तङित आत्मनेपदम्** ।१।३।१२। अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥ **स्वरितञितः कर्त्रभिप्राये क्रियाफले** ।१।३।७२। स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले ॥ **शेषात्कर्तरि परस्मैपदम्** ।१।३।७८। आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि लस्य परस्मैपदं स्यात् ॥ **तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः** ।१।४।१०१। तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञा स्युः ॥ **तान्येकवचनद्विवचनबहुवचनान्येकशः** ।१।४।१०२। लब्धप्रथमादिसंज्ञानि तिङस्त्रीणित्रीणि

---

१ ल इतीदमुच्चारणार्थाकारेण सह जातावेकवचनम् । लस्येत्यत्र तथा दृष्टत्वात् । २ फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् । ३ फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् । ४ तिप्तसझीति समाहारद्वन्द्वः । ५ क्रियाफलं च यदुद्देशेन क्रियाप्रवृत्तिरवगता तदेव ननु दक्षिणारूपम् ।

प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥ **युष्मद्युपपदे[1] समाना[2]धिकरणे स्थानिन्यपि मध्यमः** ।१।४।१०५। तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः ॥ **अस्मद्युत्तमः** ।१।४।१०७। तथाभूतेऽस्मद्युत्तमः ॥ **शेषे प्रथमः** ।१।४।१०८। मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू ति इति जाते ॥ **तिङ्शित्सार्वधातुकम्** ।३।४।११३। तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥ **कर्तरि शप्** ।३।१।६८। कर्त्रर्थे सार्वधातुके परे धातोः शप् ॥ **सार्वधातुकार्धधातुकयोः** ।७।३।८४। अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥ **झोऽन्तः** ।७।१।३। प्रत्ययावयवस्य झस्यान्तादेशः । अतो गुणे । भवन्ति । भवसि । भवथः । भवथ ॥ **अतो दीर्घो यञि** ।७।३।१०१। अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः ॥ **शेषे विभाषाऽकखादावषान्त उपदेशे** ।८।४।१८। उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन्धातावुपसर्गस्थान्निमित्तात्परस्य नेर्णत्वं वा स्यात् । प्रणिभवति ॥ **परोक्षे लिट्** ।३।२।११५। भूता[3]नद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥ **परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** ।३।४।८२। लिटस्तिबादीनां णलादयः स्युः ॥ भू अ इति स्थिते ॥ **भुवो वुग्लुङ्लिटोः** ।६।४।८८। भुवो वुगागमः स्यात् लुङ्लिटोरचि ॥ **लिटि धातोरनभ्यासस्य** ।६।१।८। लिटि परेऽनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव इति जाते ॥ **पूर्वोऽभ्यासः** ।६।१।४। अत्र ये द्वे तयोः ॥ **हलादिः शेषः**

---

१ उपोच्चरितं पदमुपपदं नतु कृत्रिमम् । तस्येहानुपयोगादप्राप्तेश्च । २ समानाधिकरणे इत्यस्य व्याख्यानं तिङ्वाच्यकारकवाचिनीति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । स्थानिनीत्यस्य व्याख्यानमप्रयुज्यमान इति । ३ व्यतीताया रात्रेः पश्चार्धेन आगामिन्याश्च पूर्वार्धेन च सहितो दिवसोऽद्यतनः तद्भिन्नोऽनद्यतनः । ४ आदिभूतादिति । अनेन च अधिकारसूत्रे द्वितीयस्येति न कर्तव्यमिति ध्वनितम् ।

।७।४।६०। अभ्यासस्यादिर्हल् शिष्यतेऽन्ये हलो लुप्यन्ते ॥ **ह्रस्वः** ।७।४।५९। अभ्यासस्याचः ॥ **भवतेरः** ।७।४।७३। भवतेरभ्यासोकारस्य अः स्याल्लिटि ॥ **अभ्यासे चर्च** ।८।४।५४। अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चर इति विवेकः । बभूव । बभूवतुः । बभूवुः ॥ **लिट् च** ।३।४।११५। लिडादेशस्तिङार्धधातुकसंज्ञः स्यात् ॥ **आर्धधातुकस्येड्वलादेः** ।७।२।३५। बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥ **अनद्यतने लुट्** ।३।३।१५। भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् ॥ **स्यतासी लृलुटोः** ।३।१।३३। धातोरेतौ स्तो लृलुटोः परतः । शबाद्यपवादः । लृ इति लृङ्लृटोर्ग्रहणम् ॥ **आर्धधातुकं शेषः** ।३।४।११४। तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥ **लुटः प्रथमस्य डारौरसः** ।२।४।८५। डित्वसामर्थ्यादभस्यापि टेर्लोपः । भविता ॥ **तासस्त्योर्लोपः** ।७।४।५०। सादौ प्रत्यये ॥ **रि च** ।७।४।५१। रादौ प्रत्यये तथा । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥ **लृट् शेषे च**[3] ।३।३।१३। भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां च । इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥ **लोट् च** ।३।३।१६२। विध्यादिष्वर्थेषु धातोर्लोट् ॥ **आशिषि लिङ्लोटौ** ।३।३।१७३ ॥ **एरुः** ।३।४।८६। लोट इकारस्य उः । भवतु ॥ **तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्** ।७।१।३५। आशिषि तुह्योः । परत्वात्सर्वादेशः । ननु ङिच्चेत्यस्य क्वावकाश इति चेच्छृणु । अनन्यार्थङकारयुक्तानङादिष्विति गृहाण । भवतात् ॥ **लोटो लङ्वत्** ।३।४।८५। लोटस्तामादयः । सलोपश्च ॥ **तस्थस्थमिपां तांतन्तामः** ।३।४।१०१। ङितश्चतुर्णां तामादयः स्युः । भवताम्

---

१ अभ्यासस्येति जातिपरो निर्देशः । तेन आततुः । आटतुः इत्यादौ तकारादिनिवृत्तिः सिध्यति । २ अन्ये इति । इतरनिवृत्तिपूर्वकावस्थानस्य शेषशब्दार्थत्वादिदमुक्तम् । ३ तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति प्रायुक्तं ततोऽन्यः शेष इत्याह—असत्यामिति । ४ विधिनिमन्त्रणेत्याद्यनुवर्तते तदाह—विध्यादिष्विति ।

भवन्तु ॥ **सेर्ह्यपिच्च** ।३।४।८७। लोटः सेर्हिः सोऽपिच्च ॥ **अतो हेः** ।६।४।१०५। लुक् । भव । भवतात्[1] । भवतम् । भवत ॥ **मेर्निः** ।३।४।८९। लोटः ॥ **आडुत्तमस्य पिच्च** ।३।४।९२। लोडुत्तमस्याट् स पिच्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि ॥ **ते प्राग्धातोः** ।१।४।८०। ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः ॥ **आनि लोट्[2]** ।८।४।१६। उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः) । दुस्थितिः । दुर्भवानि । (अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्) अन्तर्भवाणि ॥ **नित्यं ङितः** ।३।४।९९। सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः । अलोन्त्यस्येति सलोपः । भवाव । भवाम ॥ **अनद्यतने[3] लङ्** ।३।२।१११। अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् ॥ **लुङ्लङ्लृङ्क्ष्वडुदात्तः** ।६।४।७१। एष्वङ्गस्याट् ॥ **इतश्च** ।३।४।१००। ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम । **विधि[4]निमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु[5] लिङ्** ।३।३।१६१। एष्वर्थेषु धातोर्लिङ् ॥ **यासुट् परस्मैपदेषूदात्तो ङिच्च** ।३।४।१०३। लिङः परस्मैपदानां यासुडागमो ङिच्च । ङित्वोक्तेर्ज्ञायते क्वचिद्[6]नुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । तेन वक्ष्यमाणेत्यत्र ङीप्न ॥ **लिङः सलोपोऽनन्त्यस्य** ।७।२।७९। सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः । इति प्राप्ते । अ-

---

१ भवतादिति । लुगपेक्षया परत्वाद्धेस्तातङ् । अन्तरङ्गानपीति न्यायस्तु ज्ञापकसिद्धत्वादनित्य इति शब्देन्दुशखरे । २ निलोट् इत्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्यानित्यतां ज्ञापयितुम् । तेन—सागरं तर्तुकामस्य जप्त्वा स्तोत्रमित्यादि सिध्यति । ३ अनद्यतन इत्ययं बहुव्रीहिः । तेन अद्यश्वो वाभुङ्क्ष्महीत्यत्र लुङेव । ४ विधिः प्रेरणम् । भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणमावश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । ५ प्रार्थनं याञ्चा । ६ क्वचिदिति । ज्ञापकफलं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इति टिड्ढेतिसूत्र एवोक्तम् ।

तो येयः ।७।२।८०। अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् । गुणः । 'लोपो व्योर्वलि' । भवेत् । भवेताम् ॥ झेर्जुस् ।३।४।१०८। लिङः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥ लिङाशिषि ।३।४।११६। आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥ किदाशिषि[1] ।३।४।१०४। आशिषि लिङो यासुट् कित् । स्कोरिति सलोपः ॥ क्ङिति च ।१।१।५। गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥ लुङ् ।३।२।११० भूतार्थे धातोर्लुङ् ॥ माङि लुङ् ।३।३।१७५। सर्वलकारापवादः[2] ॥ स्मोत्तरे लङ् च ।३।३।१७६। स्मोत्तरे माङि लङ् स्याल्लुङ् च ॥ च्लि लुङि ।३।१।४३। शबाद्यपवादः ॥ च्लेः सिच् ।३।१।४४। गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।२।४।७७। लुक् । गापाविहेणादेशपिबती गृह्येते ॥ भूसुवोस्तिङि[3] ।७।३।८८। भू सू एतयोः सार्वधातुके तिङि गुणो न । अभूत् । अभूताम् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥ न माङ्योगे ।६।४।७४। आडाटौ न स्तः । मा भवान्भूत् । मा स्म भवत् । मा स्म भूत् ॥ लिङ्निमित्ते लृङ् क्रियातिपत्तौ ।३।३।१३९। हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यदर्थाद्धातोर्लृङ् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् । इत्यादि ज्ञेयम् । प्रभवतीत्यादौ उपसर्गाणामसमस्तत्वेपि संहिता नित्या । तदुक्तम् ।

---

१ ङित्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थम्, जागर्यादित्यत्र गुणार्थं च । जागर्तेर्गुणो हि ङिति पर्युदस्यते । ङित्वं चेह विशेषविहितेन कित्वेन बाध्यते । २ मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव नतु माङित्याहुः । ३ अत्र पितीत्यस्यानुवर्तनाननुवर्तनयोः फलदोषयोरभावेन तदनुक्तिः ।

संहितैकपदे[1] नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥

इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम्[2] । यागात्स्वर्गो भवतीत्यादौ उत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवति । इत्यादौ विलक्षणार्थावगतेः । उक्तं च ।

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ॥ १ ॥ इति ।

अत सातत्यगमने । अतति । अततः । अतन्ति । अतसि । अतथः । अतथ । अतामि । अतावः । अतामः ॥ **अत आदेः** ।७।४।७०। अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवादः[3] । आत । आततुः । आतुः । आतिथ । आतथुः । आत । आत । आतिव । आतिम । आतिता । अतिष्यति । अततु ॥ **आडजादीनाम्** ।६।४।७२। अजादेरङ्गस्याड् लुङ्-लङ्-लृङ्क्षु । आतत् । अतेत् । अत्यात् । लुङि सिचि इडागमे कृते ॥ **अस्तिसिचोऽपृक्ते**[4] ।७।३।९६। विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥ **इट ईटि** ।८।२।२८। इटः परस्य सस्य लोपः स्यादीटि । (सिज्लोप एकादेशे सिद्धो वाच्यः) । आतीत् । आतिष्टाम् ॥ **सिजभ्यस्तविदिभ्यश्च** ।३।४।१०९। सिचोभ्यस्ताद्विदेश्च परस्य ङित्संबधिनो झेर्जुस् । आतिषुः । आतीः । आतिष्टम् । आतिष्ट । आतिषम् ।

---

१ एकपदशब्देनाखण्डं पदं गृह्यते । अखण्डत्वं च पदत्वाभाववदुत्तरखण्डत्वम् । अत एव समासग्रहणं चरितार्थम् । २ उपलक्षणमिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्र च कुर्द खुर्द गुर्द गुदक्रीडायामेवेत्येवकारो ज्ञापकः । सेधतेर्गतावित्यत्र गतिग्रहणमपि षिधगत्यामित्यादि गत्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते । नान्यथेति दिक् । ३ पररूपपदमेकादेशोपलक्षणम् आनृजे इत्यादौ गुणस्यैव प्राप्तेः । ४ सिच् च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् ।

आतिष्व । आतिष्म । आतिष्यत् । एवं **अव** रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु । अवतीत्यादि । **षिध** गत्याम् ॥ **पुगन्तलघूपधस्य च** ।७।३।८६। पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः । धात्वादेरिति सः । सेधति । षत्वम् । सिषेध ॥ सेक् सृप्सृस्तृसृजस्तृस्त्यान्ये दन्त्याजन्तसादयः[1] । एकाचः षोपदेशाः ष्वष्क्ष्विद्स्वद्स्वञ्जस्वप्स्मिङः ॥ १ ॥ दन्त्यः केवलदन्त्योः न तु दन्त्योष्ठजोऽपि । ष्वष्कादीनां पृथक् ग्रहणात् ॥ **असंयोगाल्लिट् कित्** ।१।२।५। असंयोगात्परोऽपिल्लिट् कित्स्यात् । सिषिधतुः । सिषिधुः । सिषेधिथ । सिषिधथुः । सिषिध । सिषेध । सिषिधिव । सिषिधिम । सेधिता । सेधिष्यति । सेधतु । असेधत् । सेधेत् । सिध्यात् । असेधीत् । असेधिष्यत् ॥ **सात्पदाद्योः** ।८।३।१११। सातेः पदादेश्च सस्य षो न । इति निषेधे प्राप्ते ॥ **उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्**[2] ।८।३।६५। उपसर्गस्थान्निमित्तादेषां सस्य षः ॥ **सदिरप्रतेः** ।८।३।६६। प्रतिभिन्नादुपसर्गात्सिदेः सस्य षः ॥ **स्तन्भेः** ।८।३।६७ सौत्रस्य षः ॥ **अवाच्चालम्बनाविदूर्ययोः** ।८।३।६८। अवात्स्तन्भेरेतयोरर्थयोः सस्य षः ॥ **वेश्च स्वनो भोजने** ।८।३।६९। व्यवाभ्यां स्वनतेः सस्य षः ॥ **परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्** । ८।३।७०। परिनिविभ्यः परेषामेषां सस्य षः । निषेधति ॥ **प्राक्सितादड्व्यवायेऽपि**[3] ।८।३।७१। सितशब्दात्प्राग्ये सुनोत्यादयस्तेषामड्व्यवायेऽपि सस्य षः । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥ **स्थादिष्वभ्यासेन चाभ्यासस्य**[4]

---

१ सेगित्यादि । दन्त्यश्च अच्च दन्त्याचौ तौ अव्यवहितपरौ यस्य स दन्त्याजन्तः दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः स आदिर्येषां धातूनां ते । दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । २ अभिषावयतीति ण्यन्तेऽपि षत्वं भवत्येव । शब्दशक्तिमहिम्नोपसर्गाणामपि प्रकृत्यर्थ एवान्वयात् । ३ उपसर्गात्सुनोतीत्यादिना विहितं षत्वं अड्व्यवाय एवेति भ्रमनिवारणार्थमपिशब्दस्योपादानम् । ४ स्थादिष्वितीह द्वे वाक्ये । आद्यं षत्वविध्यर्थं द्वितीयं तु नियमार्थम् ।

।८।३।६४। प्राक्सितात्स्थादिष्वभ्यासेन व्यवायेपि षत्वं स्यात् एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥ **सेधतेर्गतौ**[१] ।८।३।११३। गत्यर्थस्य सेधतेः सस्य षो न । गङ्गां विसेधति । एवम् **चिती** संज्ञाने । **शुच** शोके । **गद** व्यक्तायां वाचि । गदति ॥ **नेर्गद**[२] **नद पत पद घु मा स्यति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धिषु च** ।८।३।१७। उपसर्गस्थान्निमित्तात्परस्य नेर्णत्वं स्यात् गदनदादिषु परेषु । प्रणिगदति । **कुहोश्चुः** ।७।४।६२। आभ्यासकवर्गहकारयोश्चवर्गादेशः ॥ **अत उपधायाः** ।७।२।११६। वृद्धिः स्यात् ञिति णिति च प्रत्यये । जगाद । जगदतुः । जगदुः । जगदिथ । जगदथुः । जगद ॥ **णलुत्तमो वा** ।७।१।९१। णित्स्यात् । जगाद । जगद । गदिता । गदिष्यति । गदतु । अगदत् । गदेत् । गद्यात् ॥ **अतो हलादेर्लघोः** ।७।२।७। हलादेर्लघोरतो वृद्धिर्वेडादौ सिचि परस्मैपदेषु । अगादीत् । अगदीत् । अगदिष्यत् । **णद** अव्यक्ते शब्दे ॥ **णो नः** ।६।१।६५। धात्वादेर्णस्य नः । णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्द्नक्कनॄनृतः ॥ **उपसर्गादसमासेऽपि**[३] **णोपदेशस्य** ।८।४।१४। उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । नदति । ननाद ॥ **अत एकहल्मध्येऽनादेशादेर्लिटि** ।६।४।१२०। लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि । नेदतुः । नेदुः ॥ **थलि च सेटि**

---

१ सेधतेरिति । अयं निषेधोऽनन्तरस्येतिन्यायेनादेशप्रत्ययोरित्यस्य । तेन सिषेधेत्यादौ षत्वं भवत्येवेति केचित् । २ नेर्गदनद—गदादीनां चतुर्णां शपा निर्देशः स्यत्यादीनामेकादशानां श्तिपा निर्देशश्च यङ्लुङ्निवृत्त्यर्थः । तेन प्रनिजागदीति प्रनिनानदीति प्रनिसातीति प्रनिजङ्घनीति इत्यादौ णत्वं न । घुशब्देन घुसंज्ञका दाधादयः षट् गृह्यन्ते । डुदाञ् प्रणिददाति । दाणू प्रणियच्छति । दो प्रणिद्यति । देङ् प्रणिदयते । धेट् प्रणिधयति । डुधाञ् प्रणिदधाति । माशब्देन मेङ्माङोरेव ग्रहणं । घुप्रकृतिमाङ् इति पठित्वा भाष्यादौ तथा व्याख्यानात् । ३ समासेऽङ्गुलेः सङ्गः इत्यतोनुवर्तनात्समास एव स्यादित्यसमासग्रहणम् । कृते तु तस्मिन् असमास एव स्यादित्यपेर्ग्रहणं कृतम् ।

।६।४।१२१। इड्वति थलि प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद। ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्। अनदीत्। अनदिष्यत्। **श्च्युतिर्** क्षरणे। (इर इत्संज्ञा वाच्या)॥ **शर्पूर्वाः खयः**[1] ।७।२।६१। शिष्यते अभ्यासस्य। हलादिःशेषापवादः। चुश्च्योत॥ **इरितो वा** ।१।३।५७। इरितो धातोश्च्लेरङ् वा परस्मैपदेषु। अश्च्युतत्। अश्च्योतीत्। यकाररहितोऽप्ययम्। श्चोतति। चुश्चोत। अश्चोतत्। अश्चोतीत्। **च्युचिर्** आसेचने। च्योतति। **टुनदि** समृद्धौ॥ **आदिर्ञिटुडवः** ।१।३।५। उपदेशे धातोराद्या एते इतः स्युः॥ **इदितो नुम् धातोः**[2] ।७।१।५८। नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। इदित्वान्नलोपो न। नन्द्यात्। अनन्दीत् अनन्दिष्यत्। एवं **कुथि पुथि लुथि मथि** हिंसासंक्लेशनयोः। **बिदि** अवयवे। बिन्दति। **भिदीति** पाठान्तरम्। भिन्दति। **गडि** वदनैकदेशे। गण्डति। **चदि** आह्लादने। चन्दति। **त्रदि** चेष्टायाम्। त्रन्दति। **कदि क्रदि क्लदि** आह्वाने रोदने च। **क्लिदि** परिदेवने। **तकि** कृच्छ्रजीवने॥ **युगि जुगि वुगि** वर्जने। **मघि** मण्डने। **शिघि** आघ्राणे। **मन्थ** विलोडने। मन्थति। ममन्थ। कित्वान्नलोपः। मथ्यात्। **अर्च** पूजायाम्। अर्चति॥ **तस्मान्नुड् द्विहलः** ।७।४।७१। द्विहलो धातोर्दीर्घीभूतादकारात् परस्य नुट्। आनर्च। आनर्चतुः। आनर्चुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्। एवं **अर्द** गतौ याचने च। **अति अदि** बन्धने। **वन षण** संभक्तौ। वनति। ववान॥ **न शसददवादिगुणानाम्**[3] ।६।४।१२४। शसेर्ददेर्वकारादीनां

---

१ अतद्गुणसंविज्ञानोऽयं बहुव्रीहिः। तेन शरो न शेषः किंतु खयामेव। इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति। द्वितीयस्यैकाचः संबन्धि रेफस्यैव नन्द्रा इति निषेधादिति बोध्यम्।
२ इदित इति कर्मधारयेण धातोर्विशेषणम्। तेन इदिन्तस्य धातोर्नुम्विधानाच्चक्षिङादौ न दोषः।
३ नशसदद—शसु हिंसायां दन्त्यान्तः सूत्रेऽवयवावयविभावः षष्ठ्यर्थः। तथाच शसददवादीनां योकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाच्छेदनिबन्धना षष्ठी न संभवतीत्याशङ्क्य तन्निर्वाहार्थं व्याचष्टे—गुणशब्देन भावितस्येति। भावितत्वं च साक्षात्परपरासाधारणम्।

गुणशब्देन भावितो योऽत् तस्य च एत्वाभ्यासलोपौ न । ववनतुः । ववनुः । सनति । ससान । सेनतुः । सेनुः ॥ **ये विभाषा** ।६।४।४३। जनसनखनामात्वं वा यादौ क्ङिति । सायात् । सन्यात् ॥ **वज व्रज गतौ** । व्रजति । वव्राज । व्रजिता । व्रजिष्यति । व्रजतु । अव्रजत् । व्रजेत् । व्रज्यात् ॥ **वदव्रजहलन्तस्याचः** ।७।२।३। एषामचो वृद्धिः परस्मैपदे सिचि । अव्राजीत् । अव्रजिष्यत् । **कटे** वर्षावरणयोः । कटति । चकाट । कटिता । कटिष्यति । कटतु । अकटत् । कटेत् । कट्यात् ॥ **ह्मयन्तक्षणश्वसजागृणिश्व्येदिताम्** ।७।२।५। ह्मयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि । अकटीत् । अकटिष्यत् । **गुपू** रक्षणे ॥ **गुपूधूपविच्छिपणिपनिभ्य आयः** ।३।१।२८। स्वार्थे ॥ **सनाद्यन्ता धातवः** ।३।१।३२। सनादयः कर्मेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः ।

सन् क्यच् काम्यच् क्यङ् क्यषोऽथाचारक्विब् णिज्यङौ तथा ।
यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः ॥ १ ॥

सनाद्यन्ता धातव इत्यस्यानन्तरं भूवादय इत्येव सूत्रयितुं युक्तम् । धातुत्वाल्लडादयः । गोपायति ॥ **आयादय आर्धधातुके वा** ।३।१।३१। आर्धधातुकविवक्षायामाययेङ्णिङो वा स्युः । (कास्यनेकाच आम्वक्तव्यो लिटि) । कास आम्विधानान्मस्य नेत्वम् ॥ **अतो लोपः** । ६।४।४१। आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके ॥ **आमः** ।२।४।८१। आमः परस्य लुक् ॥ **कृञ्चानुप्रयुज्यते लिटि** ।३।१।४०। आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते तेषां

---

१ तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । हलोऽच इत्युक्ते त्वजन्ताङ्गस्य हलः स्थाने वृद्धिरिति कदाचिदाशङ्क्येत । अच इति तु इक्परिभाषाया अनुपस्थानार्थम् । अन्यथा अभैत्सीदित्यत्र स्यान्न त्वपाक्षीदीत्यादौ । २ प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः । ३ एतदुत्तरं सिद्धान्तकौमुद्यां आम्प्रत्ययवत्कृञोऽनुप्रयोगस्येति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोग इत्यतः कृञो द्वितीयेति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते ।

द्वित्वादि ॥ **उरत्** ।७।४।६६। अभ्यासस्य ऋतोऽत्स्यात्प्रत्यये । वृद्धिः । गोपायांचकार । द्वित्वात्परत्वाद्यणि प्राप्ते ॥ **द्विर्वचनेऽचि** ।१।१।५९। द्वित्वनिमित्तेऽचि परे अच आदेशो न द्वित्वे कर्तव्ये । गोपायांचक्रतुः । गोपायांचक्रुः ॥ **एकाच उपदेशेऽनुदात्तात्** ।७।२।१०। उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्यार्धधातुकस्येण् न[1] ।

ऊदॄदन्तैर्यौतिरुक्ष्णुशीस्नुनुक्षुश्विडीङ्श्रिभिः ।
वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ १ ॥

कान्तेषु । शक्ल एकः । **चान्तेषु** । पच् । मुच् । रिच् । वच् । विच् । सिच्-एते षट् । **छान्तेषु** प्रच्छ्येकः ॥ **जान्तेषु** । त्यज् । निंजिर् । भज् । भञ्ज् । भुज् । भ्रस्ज् । मस्ज् । यज् । युज् । रुज् । रञ्ज् । विजिर् । सञ्ज । स्वञ्ज । सृजः । पञ्चदश ॥ **दान्तेषु** । अद् । क्षुद् । खिद् । छिद् । तुद् । नुद् । पद्य । भिद् । विद्य । विनद् । शद् । सद् । स्विद्य । स्कन्द । हद् । षोडश ॥ **धान्तेषु** । क्रुध् । क्षुध् । बुध्य । बन्ध् । युध् । रुध् । राध् । व्यध् । शुध् । साध् । सिध्य । एकादश ॥ **नान्तेषु** । मन्यहनौ द्वौ ॥ **पान्तेषु** । आप् । क्षिप् । छुप् । तप् । तिप् । तृप्य । दृप्य । लिप् । लुप् । वप् । शप् । स्वप् । सृप् । त्रयोदश ॥ **भान्तेषु** । यभ् । रभ् । लभ् । त्रयः ॥ **मान्तेषु** । गम् । नम् । रम् । यम् । चत्वारः ॥ **शान्तेषु** । क्रुश् । दंश् । दिश् । दृश् । मृश् । रिश् । रुश् । लिश् । विश् । स्पृश् । दश ॥ **षान्तेषु** । कृष् । त्विष् । तुष् । द्विष् । दुष् । पुष्य । पिष् । विष् । शिष् । शुष् । श्लिष्य एकादश ॥ **सान्तेषु** घस्वसती द्वौ ॥ **हान्तेषु** । दह् । दुह् । दिह् । नह् । मिह् । रुह् । लिह् । वह् अष्टौ । अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् । गोपायांचकर्थ । गोपायांचक्रथुः । गोपायांचक्र । गोपायांचकार । गोपायांचकृव[2] । गोपायांचकृम । गोपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । जुगुपुः ॥ **स्वरतिसूतिसूयतिधूञूदितो वा** ।७।२।४४। स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा । जुगोपिथ

१ अनेन जागृदीधीत्यादीनां व्यावृत्तिः । २ अत्र गुणाभावश्छान्दसः ।

जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपायिष्यति । गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाय्यात् । गुप्यात् । अगोपायीत् ॥ **नेटि** ।७।२।४। इडादौ सिचि [1]हलन्तलक्षणा वृद्धिर्न । अगोपीत् । अगौप्सीत् ॥ **झलो झलि** ।८।२।२६। झलः परस्य सस्य लोपः स्याज्झलि । अगौप्ताम् । अगौप्सुः । अगौप्सीः । अगौप्तम् । अगौप्त । अगौप्सम् । अगौप्स्व । अगौप्स्म । अगोपायिष्यत् । अगोप्सिष्यत् । अगोप्स्यत् । **क्षि** क्षये । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । एकाच इति निषेधे प्राप्ते ॥ **कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि** ।७।२।१३। [2]क्रादिभ्य एव लिट इण्नस्यादन्यस्माद्निटोऽपि स्यात् ॥ [3]**अचस्तास्वत्थल्यनिटो नित्यम्** ।७।२।६१। उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न ॥ **उपदेशेऽत्वतः** ।७।२।६२। उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न ॥ **ऋतो भारद्वाजस्य** ।७।२।६३। तासौ नित्यानिट ऋदन्तस्यैव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य तु स्यादेव । अयमत्र संग्रहः ।

अजन्तोऽ[4]कारवान्वा यस्तास्यनिट् थलि वेडयम् ।
ऋदन्त ई[5]दृङ् नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥ १ ॥

चिक्षयिथ । चिक्षेथ । चिक्षियथुः । चिक्षिय । चिक्षाय । चिक्षय । चिक्षियिव । चिक्षियिम । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ॥ **अकृत्सार्वधातुकयोर्दीर्घः** ।७।४।२५। अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । क्षीयात् ॥ **सिचि वृद्धिः परस्मैपदेषु** ।७।२।१। इगन्ताङ्गस्य वृद्धिः परस्मैपदपरे सिचि ।

---

१ अयं हलन्तलक्षणाया एव वृद्धेर्निषेधः । वदव्रजोस्तु विशिष्यविधानान्न निषेधः । २ क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थं । कृसृभृ एषामनुदात्तत्वात् 'एकाच उपदेशे' इति प्रकृत्याश्रये निषेधे प्राप्ते वृङ्वृञोस्तूदात्तत्वात् 'श्र्युकः किति' इति प्रत्ययाश्रये च निषेधे प्राप्ते नियमार्थमिदम् । ३ तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति तथा थल्यपीत्यर्थः । ह्रस्वाकारवानित्यर्थः । ५ यस्तास्यनिट् स ऋदन्तः थलि नित्यानिट् भवतीत्यर्थः ।

अक्षैषीत् । अक्षेष्यत् ॥ **तप** सन्तापे । तपति । तताप । तेपतुः । तेपुः । तेपिथ । ततप्थ । तप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीत् । अताप्ताम् । अतप्स्यत् ॥ **निसस्तपतावनासेवने** ।८।३।१०२। षः स्यात् । आसेवनं पौनःपुन्यं ततोन्यस्मिन्विषये । निष्टपति ॥ **क्रमु** पादविक्षेपे ॥ **वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः** ।३।१।७०। एभ्यः श्यन्वा कर्तरि सार्वधातुके । पक्षे शप् ॥ **क्रमः परस्मैपदेषु** ।७।३।७८। क्रमेर्दीर्घः परस्मैपदे शिति । क्राम्यति । क्रामति । चक्राम ॥ **स्नुक्रमोरनात्मनेपदनिमित्ते** ।७।२।३६। अत्रैवेट् । क्रमिता । क्रमिष्यति । क्राम्यतु । क्रामतु । अक्राम्यत् । अक्रामत् । क्राम्येत् । क्रामेत् । क्रम्यात् । अक्रमीत् । अक्रमिष्यत् ॥ **चमु छमु जमु झमु** अदने ॥ **ष्ठिवुक्लमुचमां शिति** ।७।३।७५। अचो दीर्घः । (आङि चम इति वक्तव्यम्) आचामति । आङि किम् । चमति । विचमति । अचमीत् ॥ **स्खल** संचलने । स्खलति । चस्खाल ॥ **अतो ल्रान्तस्य** ।७।२।२। अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः परस्मैपदे सिचि । अस्खालीत् । अस्खलिष्यत् ॥ **त्सर** छद्मगतौ । अत्सारीत् ॥ **पा** पाने ॥ **पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः** । ।७।३।७८। पादीनां पिबादयः स्युरित्संज्ञकशादौ प्रत्यये । पिबादेशोऽदन्तस्तेन न गुणः । पिबति ॥ **आत औ णलः** ।७।१।३४। आदन्ताद्धातोर्णल औकारादेशः । पपौ ॥ **आतो लोप इटि च** ।६।४।६४। अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः । पपतुः । पपुः । पपिथ । पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् ॥ **एर्लिङि** ।६।४।६७। घुसंज्ञानां मास्थागैपिबतिजहातिस्यतीनां चात एत्वमार्धधातुके किति लिङि ।

---

१ उभयत्रविभाषेयम् अनवस्थानार्थो भ्रमिः । क्लमित्रसी च दिवादी । तेभ्यो नित्यं प्राप्ते इतरेषामप्राप्ते चारम्भात् । २ स्नुक्रमोरुदात्तत्वादिटि सिद्धे नियमार्थोऽयमित्याह—अत्रवेडिति । ष्ठिवुक्लमुआचमामिति वृत्तिकारोक्तपाठोऽयुक्त इति भावः । ल्रान्तस्येत्यागन्तुकेनाकारेण निर्देशः । क्वचिद्भाष्ये ल्रान्तस्येत्यपि पाठः ।

पेयात् । गातिस्थेति सिचो लुक् । अपात् । अपाताम् ॥ **आतः** ।३।४।११०। सिज्लुकि आदन्तादेव झेर्जुस् ॥ **उस्यपदान्तात्** ।६।१।९६। अपदान्तादवर्णादुसि पररूपमेकादेशः । अपुः । अपास्यत् । **ग्लै म्लै** हर्षक्षये । ग्लायति ॥ **आदेच उपदेशेऽशिति** ।६।१।४५। उपदेशे एजन्तस्य धातोरात्वं न तु शिति । जग्लौ । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् ॥ **वान्यस्य संयोगादेः** ।६।४।६८। घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा आर्धधातुके किति लिङि । ग्लेयात् । ग्लायात् ॥ **यमरमनमातां सक् च** ।७।२।७३। एषां सक् स्यादेभ्यः सिच इट् परस्मैपदेषु । अग्लासीत् । अग्लास्यत् । एवं म्लायति ॥ **धेट्** पाने । धयति । दधौ ॥ **दाधाघ्वदाप्**[1] ।१।१।२०। दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना । धेयात् ॥ **विभाषा धेट्श्व्योः** ।३।१।४९। आभ्यां च्लेश्चङ् वा ॥ **चङि** ।६।१।११। अनभ्यासधात्ववयवस्य प्रथमस्यैकाचो द्वे स्तोजादेर्द्वितीयस्य । अदधत् । अदधताम् ॥ **विभाषा घ्राधेट्शाच्छासः** ।२।४।७८। एभ्यः सिचो लुग्वा परस्मैपदेषु । अधात् । अधाताम् । अधुः[2] । पक्षे इट्सकौ । अधासीत् । अधासिष्टाम् । अधासिषुः ॥ **दै** न्यक्करणे[3] । दायति ॥ **द्रै** स्वप्ने । द्रायति ॥ **ध्रै** तृप्तौ । ध्रायति ॥ **ध्यै** चिन्तायाम् । ध्यायति ॥ **रै** शब्दे । रायति ॥ **स्त्यै ष्ट्यै** शब्दसङ्घातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासतीत्यादौ भविष्यति ॥ **खै** खदने । खायति ॥ **क्षै जै षै** क्षये । क्षायति । जायति । सायति । घुमास्थेत्यत्र 'विभाषा घ्राधेट्' इत्यत्र च सतेरेव ग्रहणं न त्वस्य तेन एत्वसिज्लुकौ न । सायात् । असासीत् ॥ **कै गै** शब्दे ॥ **शै श्रै** पाके ॥ **पै ओवै** शोषणे । पायात् । अपासीत् । घुमास्थेतीत्वं तदपवाद एर्लिङीत्येत्वं गातिस्थेति सिज्लुकौ च न । (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्) इति पारूपस्य लाक्षणिकत्वात् ॥ **ष्टै** वेष्टने ।

---

१ अनुबन्धानामनेकान्तत्वादादेच उपदेश इत्यात्वे दोदेङ्धेटामनुकरणे दाधारूपत्वमस्ति । एवं च दाश्च दाश्च दाः । धाश्च धाश्च धौ दाश्च धौ च दाधाः इति विग्रहः । २ अधुरिति । आतः इति झेर्जुस् । ३ न्यक्करणं तिरस्करणम् ।

स्त्यायति ॥ स्त्यै वेष्टने । शोभायां चेत्येके । स्नायति ॥ दैप् शोधने । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् ॥ घ्रा गन्धोपादाने । जिघ्रति । घ्रायात् । घ्रेयात् । अघ्रात् । अघ्रासीत् । अघ्रासत् ॥ ध्मा शब्दाग्निसंयोगयोः । धमति ॥ ष्ठा गतिनिवृत्तौ । तिष्ठति । स्थादिष्विति षत्वम् । अधितष्ठौ । उपसर्गादिति षत्वम् । अधिष्ठाता । स्थेयात् । सत्वे कृते प्रकृतिस्तवर्गः स्यात् ।

नकारजावनुस्वारपञ्चमौ झलि धातुषु ।
सकारजः शकारश्च षाट्टवर्गस्तवर्गजः ।

गातिस्थेति सिचो लुक् । अस्थात् ॥ म्ना अभ्यासे । मनति ॥ दाण् दाने । प्रणियच्छति ॥ ह्वृ कौटिल्ये । ह्वरति ॥ **ऋतश्च संयोगादेर्गुणः** ।७।४।१०। ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि । उपधाया वृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । जह्वरथुः । जह्वर । जह्वार । जह्वर । जह्वरिव । जह्वरिम । ह्वर्ता ॥ **ऋद्धनोः स्ये** ।७।२।७०। ऋतो हन्तेश्च स्यस्य इट् । ह्वरिष्यति । ह्वरतु । अह्वरत् । ह्वरेत् ॥ **गुणोर्तिसंयोगाद्योः** ।७।४।२९। अर्तेः संयोगादेर्ऋदन्तस्य च गुणो यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । अह्वरिष्यत् ॥ स्वृ शब्दोपतापयोः । स्वरति । स्वरतीति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु स्वरत्यादिविकल्पं बाधित्वा पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्याच्छ्र्युकः कितीति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम । परत्वादृद्धनोरिति नित्यमिट् । स्वरिष्यति ॥ स्मृ चिन्तायाम् । स्मरति ॥ ह्वृ संवरणे । ह्वरति ॥ सृ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । ससृम ॥ **रिङ्शयग्लिङ्क्षु** ।७।४।२८। शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् । रीङि प्रकृते रिङ्विधिसामर्थ्यान्न दीर्घः । स्रियात् । असार्षीत् । शीघ्रगतौ तु पाघ्रेति शिति धौरादेशः । धावति ॥ गृ घृ सेचने । ध्वृ हूर्च्छने । ध्वरति ॥ दृशिर् प्रेक्षणे । प-

---

१ अत्र तपरकरणं स्पष्टार्थम् । स्तृञ् इत्यादेर्लिटि तस्तरतुरित्यादौ ऋच्छत्यॄतामिति गुणस्य जायमानत्वात् । २ अर्तीति भ्वादिस्वाद्योर्ग्रहणम् । लुका निर्देशस्तु सौत्र ऋग्रहणे कर्तव्ये यङ्लुङ्निवृत्त्यर्थः ।

श्यति ॥ **विभाषा सृजिदृशोः** ।७।२।६५। आभ्यां थल इड् वा ॥ **सृजिदृशोर्झल्यमकिति** ।६।१।५८। अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ ॥ **षढोः कः सि** ।८।२।४१। द्रक्ष्यति । दृश्यात् । इरित्त्वादङ्वा ॥ **ऋदृशोऽङि गुणः** ।७।४।१६। अदर्शत् ॥ **न दृशः** ।३।१।४७। च्लेर्वक्ष्यमाणः क्सो न । अद्राक्षीत् । अद्रक्ष्यत् । श्रु श्रवणे ॥ **श्रुवः शृ च** ।३।१।७४। श्रुवः शृ आदेशः श्नुप्रत्ययश्च कर्तरि सार्वधातुके । शृणोति ॥ **सार्वधातुकमपित्** ।१।२।४। अपित्सार्वधातुकं ङिद्वत्स्यात् । शृणुतः ॥ **हुश्नुवोः सार्वधातुके** ।६।४।८७। जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्यासंयोगपूर्वस्योवर्णस्य यण्स्यादचि सार्वधातुके । शृण्वन्ति । शृणोषि । शृणुथः । शृणुथ । शृणोमि ॥ **लोपश्चास्यान्यतरस्यां म्वोः** ।६।४।१०७। असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । शुश्रोथ । शुश्रविथ । शुश्रुवथुः । शुश्रुव । शुश्राव । शुश्रव । शुश्रुव । शुश्रुम । श्रोता । श्रोष्यति । शृणोतु । शृणुतात् । शृणुताम् । शृण्वन्तु ॥ **उतश्च प्रत्ययादसंयोगपूर्वात्** ।६।४।१०६। असंयोगपूर्वात्प्रत्ययोतो हेर्लुक् । शृणु । शृणुतम् । शृणुत । गुणावादेशौ । शृणवानि । शृणवाव । शृणवाम । अशृणोत् । अशृणुताम् । अशृण्वन् । अशृणोः । अशृणुतम् । अशृणुत । अशृणवम् अशृण्व । अशृणुव । अशृण्म । अशृणुम । शृणुयात् । शृणुयाताम् ॥ **उस्यपदान्तात्** ।६।१।९६। अपदान्तादवर्णादुसि पररूपमेकादेशः स्यात् । शृणुयुः । शृणुयाः । शृणुयातम् । शृणुयात । शृणुयाम् । शृणुयाव । शृणुयाम । श्रूयाम् अश्रौषीत् । अश्रोष्यत् ॥ **गम्लृ सृप्लृ** गतौ । **इषुगमियमां छः** ।७।३।७७। शिति । गच्छति । जगाम ॥ **गमहनजनखनघसां लोपः क्ङित्यनङि** ।६।४।९८। एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । जग्मथुः । जग्म । जगाम । जगम । जग्मिव । जग्मिम । गन्ता ॥ **गमेरिट् परस्मैपदेषु** ।७।२।५८। गमेः

---

१ क्रादिनियमान्नित्ये प्राप्ते विभाषेयम् । २ यद्ययं धातुः स्वादौ पठ्येत तर्हि चकारो न कर्तव्य इति लाघवमाहुः ।

सादेरार्धधातुकस्येट् परस्मैपदेषु । गमिष्यति । गच्छतु । अगच्छत् । गम्यात् ॥ **पुषादिद्युताद्य्लृदितः परस्मैपदेषु** ।३।१।५४। श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ् परस्मैपदेषु । अगमत् । अगमिष्यत । सर्पति ॥ **अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्** ।६।१।५९। उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा झलादावकिति । स्रप्ता । सर्प्ता । असृपत्[2] ॥ **ञिक्ष्विदा** अव्यक्ते शब्दे । क्ष्वेदति ॥ **यभ** मैथुने । यभति । वेट् येभिथ ॥ **झषस्तथोर्धोऽधः** ।८।२।४०। झषः परयोस्तथयोर्धः स्यात् न तु दधातेः । ययब्ध । यब्धा ॥ **णम** प्रह्वत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । नंस्यति । अनंसीत् । अनंसिष्टाम् ॥ **त्यज** हानौ । त्यजति । तत्याज । तत्यजिथ । तत्यक्थ । त्यक्ता । अत्याक्षीत् । अत्याक्ताम् । अत्यक्ष्यत् ॥ **अक्षू** व्याप्तौ ॥ **अक्षोऽन्यतरस्याम्** ।३।१।७५। श्नुर्वा स्यात्कर्तरि सार्वधातुके । पक्षे शप् । अक्ष्णोति । अक्षति । आनक्ष । आनक्षिथ । आनष्ठ । अक्षिता । अष्टा । अक्षिष्यति । स्कोरिति कलोपः ॥ **षढोः कः सि** ।८।२।४१। अक्ष्यति अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । आक्ष्णोत् । आक्ष्णवम् । अक्ष्णुयात् । अक्ष्णुयाताम् । अक्ष्णुयुः । अक्ष्यात् । आक्षीत् । आक्षिष्टाम् ॥ **तक्षू त्वक्षू** तनूकरणे ॥ **तनूकरणे तक्षः** ।३।१।७६। श्नुर्वा शब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्ष । ततक्षिथ ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत्[3] । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः ॥ **रक्ष** पालने । रक्षति ॥ **णिक्ष** चुम्बने । प्रणिक्षति ॥ **वक्ष** रोषे । संघात इत्येके । वक्षति । **मृक्ष** संघाते । **मक्ष** इत्येके ॥ **तक्ष** त्वचने । त्वचनं संवरणम् त्वचो ग्रहणं च ॥ **पक्ष** परिग्रह इत्येके ॥ **सूर्क्ष** आदरे । सुसूर्क्ष ॥ **काक्षि वाक्षि माक्षि** काङ्क्षायाम् ॥ **द्राक्षि ध्राक्षि ध्वाक्षि** घोरवासिते च ॥ **चूष** पाने ॥ **तूष** तुष्टौ ॥ **पूष** वृद्धौ ॥ **मूष** स्तेये ॥ **लूष रूष** भूषायाम् ॥ **शूष** प्रसवे ।

---

१ पुषधातुर्भ्वादौ दिवादौ क्र्यादौ चुरादौ च पठ्यते । यदि तु पुष पुष्टाविति भौवादिकधातुमारभ्य पुषादिगणो गृह्येत तदा द्युतादिग्रहणमनर्थकं भवेत् । अतो दिवादीनामेव ग्रहणम् । २ ऌदित्त्वादङ् । स्पृशमृशेति सिज्विकल्पवार्तिके सृपं प्रक्षिप्य अस्राप्सीदिति केचिदुदाहरन्ति तत्प्रामादिकम् । ३ नेटीति वृद्धिनिषेधः । इडभावे तु अताक्षीत् ।

यूष हिंसायाम् ॥ **जूष च** ॥ **भूष** अलंकारे ॥ **जि** जये । जयति ॥ **संल्लिटोर्जेः** ।७।६।५७। संल्लिण्निमित्तादभ्यासात्परस्य जेः कुत्वम् । जिगाय । जिग्यतुः । जिगयिथ ॥ **जीव** प्राणधारणे । जीवति ॥ **पीव मीव तीव णीव** स्थौल्ये । पीवति । पिपीव ॥ **मुर्वी** बन्धने ॥ **उपधायां च** ।८।२।७८। धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । मूर्वति ॥ **पूर्व पर्व मर्व** पूरणे । पूर्वति । पर्वति । मर्वति ॥ **चर्व** अदने । चर्वति ॥ **कष खष शिष जष झष शष चष मष रुष रिष** हिंसार्थाः । शेषति । शिशेष । शेष्टा ॥ **शल**[1] **इगुपधादनिटः क्सः** ।३।१।४५। इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः । अशिक्षत् ॥ **तीषसहलुभरुषरिषः** ।७।२।४९। इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा । रोषिता । रोष्टा ॥ **भष** भर्त्सने । इह भर्त्सनं श्वरवः ॥ **पुष** पुष्टौ । पोषिता । अनुदात्तेषु पुष्येति श्यना निर्देशादयमुदात्तः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् । अपोषीत् ॥ **श्रिषु श्लिषु प्रुषु प्लुषु** दाहे । शेषति । श्रेषति प्रोषति । प्लोषति ॥

॥ **इति परस्मैपदिनः** ॥

एध वृद्धौ ॥ **टित आत्मनेपदानां टेरे** ।३।४।७९। टितो लस्यात्मनेपदानां टेरेत्वम् । एधते ॥ **आतो ङितः** ।७।२।८१। अतः परस्य ङितामात इय् स्यात् । एधेते । एधन्ते ॥ **थासस्से**[2] ।३।४।८०। टितो लस्य । एधसे । एधेथे । एधध्वे । एधे । एधावहे । एधामहे ॥ **इजादेश्च गुरुमतोऽनृच्छः** ।३।१।३६। इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् लिटि ॥ **आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य** ।१।३।६३। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोप्यात्मनेपदं स्यात् ॥ **लिटस्तझयोरेशिरेच्**[3] ।३।४।८१। ऐकारोच्चारणं ज्ञापकम् । तङादेशानां टेरेत्वं नेति । तेन

---

१ शल इति धातोर्विशेषणादन्तलाभः । २ एकारोच्चारणं ज्ञापनार्थमिति लिटस्तझयोरित्यत्र स्फुटीभविष्यति । ३ एशिति शकारकरणमकारविशिष्टतकारस्यादेशत्वाय । ४ नच लिटस्तझयोरेशिरेजित्येवमेव मात्रालाघवेन पठितव्यं पश्चाच्च टित आत्मनेपदानां टेरे इत्यनेनैत्व भविष्यत्येवेत्यत उक्तं एकारोच्चारणं ज्ञापकमिति । तथाचैकारोच्चारणं व्यर्थं सज्ज्ञापयति तङादेशानां टेरेत्वं नेति । अत एव डारौरसां नैत्वम् ॥

डारौरसां न एधांचक्के । एधांचक्राते । एधांचक्रिरे । एधांचकृषे । एधांचक्राथे ॥ **इणः षीध्वंलुङ्लिटां धोऽङ्गात्** ।८।३।७८। इण्णन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । एधांबभूव । एधामास । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि कृश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् । एधिता । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥ **धि च** ।८।२।२५। धादौ प्रत्यये सलोपः । एधिताध्वे ॥ **ह एति** ।७।४।५२। तासस्त्योः सस्य हः स्यात् । एधिताहे । एधितास्वहे । एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥ **आमेतः** ।३।४।९०। लोट एत आम् । एधताम् । एधेताम् । एधन्ताम् ॥ **सवाभ्यां वामौ** ।३।४।९१। सवाभ्यां परस्य लोडेतः क्रमाद्वामौ स्तः । एधस्व । एधेथाम् । एधध्वम् । ॥ **एत ऐ** ।३।४।९३। लोडुत्तमस्य । एधै । एधावहै । एधामहै । 'आटश्च' । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥ **लिङः सीयुट्** ।३।४।१०२। लिङः सलोपोऽनन्त्यस्येति सलोपः ॥ **लोपो व्योर्वलि** ।३।४।१७०। एधेत । एधेयाताम् ॥ **झस्य रन्** ।३।४।१०५। लिङः । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥ **इटोऽत्** ।३।५।१०६। लिङादेशस्य । एधेय । एधेवहि । एधेमहि ॥ **सुट् तिथोः** ।३।४।१०७। लिङस्तथोः सुट् । यलोपः । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥ **आत्मनेपदेष्वनतः** ।७।१।५। अनकारात्परस्यात्मनेपदेषु झस्यात् स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । ऐधिढ्वम् । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये ।

---

१ षीध्वमिति शकारोच्चारणं तु ब्रुवीध्वमित्यत्रैकदेशविकृतन्यायेन सीध्वमःसत्वादतिव्याप्तिवारणार्थम् । २ प्रत्यय इति । तेन पयो धावतीत्यादौ न सिलोपः । ३ इणः परत्वेपि इण्णन्तादङ्गात्परत्वाभावात् इणः षीध्वमिति ढत्वं न भवति ।

एधिष्यावहि । एधिष्यामहि ॥ **कमु** कान्तौ ॥ **कमेर्णिङ्** ।३।१।३०। स्वार्थे । कामयते ॥ **अयामन्ताल्वाय्येत्न्विष्णुषु** ।६।४।५५। एषु[1] णेरय् । कामयांचक्रे । आयादय इति वा णिङ् । चकमे । चकमाते । चकमिरे । चकमिषे । चकमाथे । चकमिध्वे । चकमे । चकमिवहे । चकमिमहे । कामयिता । कमिता । कामयिष्यते । कमिष्यते । कामयताम् । अकामयत । कामयेत । कामयिषीष्ट । कमिषीष्ट ॥ **णिश्रिद्रुस्रुभ्यः कर्तरि चङ्** ।३।१।४८। ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् कर्त्रर्थे लुङि । अकाम इ अ त इति स्थिते ॥ **णेरनिटि**[2] ।६।४।५१। अनिडादावार्धधातुके परे णेर्लोपः ॥ **णौ चङ्युपधाया ह्रस्वः** ।७।४।१। चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः ॥ **सन्वल्लघुनि चङ्परेऽनग्लोपे** ।७।४।९३। चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति ॥ **सन्यतः** ।७।४।७९। अभ्यासस्यात इत्सनि ॥ **दीर्घो लघोः** ।७।४।९४। लघोरभ्यासस्य दीर्घः सन्वद्भावविषये । अचीकमत । णिङभावपक्षे । (कमेश्च्लेश्चङ् वाच्यः) । अचकमत । अकामयिष्यत । अकमिष्यत ॥ **भाम** क्रोधे । भामते । बभामे ॥ **क्षमूष्** सहने । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिवहे । चक्षमिमहे ॥ **म्वोश्च** ।८।२।६५। मान्तस्य धातोर्मस्य नः स्यान्म्वोः परयोः । चक्षण्वहे । चक्षण्महे ॥ **गाधृ** प्रतिष्ठालिप्सयोर्ग्रन्थे च । गाधते ॥ **बाधृ** लोडने । लोडनं प्रतिघातः । बाधते ॥ **नाथृ नाधृ** याच्ञोपतापैश्वर्याशीःषु । (आशिषि नाथ इति वाच्यम्) अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाथते ॥ **दध** धारणे । दधते ॥ **स्कुदि** आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च । स्कुन्दते । चुस्कुन्दे ॥ **श्विदि** श्वैत्ये । श्विन्दते । शिश्विन्दे ॥ **वदि** अभिवादनस्तुत्योः । वन्दते । ववन्दे ॥ **भदि** कल्याणे सुखे च । भन्दते । बभन्दे ॥ **मदि** स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते ॥ **स्पदि** किंचिच्चलने । स्पन्दते । पस्पन्दे ॥ **मुद** हर्षे । मोदते । मुमुदे ॥ **उर्द** माने क्रीडायां च । ऊर्दते । ऊर्दांचक्रे ॥ **कुर्द खुर्द गुर्द गुद**

---

१ आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । २ णेरिति णिङ्णिचोर्ग्रहणम् । एवमन्यत्रापि बोध्यम् ।

क्रीडायामेव । कूर्दते । खूर्दते । गूर्दते । गोदते । जुगुदे ॥ **षूद** क्षरणे । सूदते । सुषूदे ॥ **ह्राद** अव्यक्ते शब्दे । ह्रादते । जह्रादे । **ह्लादी** सुखे च । चादव्यक्ते शब्दे । ह्लादते ॥ **स्वाद** आस्वादे । स्वादते । **पर्द** कुत्सिते शब्दे । गुदरव इत्यर्थः । पर्दते । पपर्दे ॥ **यती** प्रयत्ने । यतते । येते ॥ **श्रथि** शैथिल्ये । श्रन्थते ॥ **ग्रथि** कौटिल्ये । ग्रन्थते ॥ **कत्थ** श्लाघायाम् । कत्थते । चकत्थे ॥ **श्लोकृ** संघाते । संघातो ग्रन्थः । सचेह ग्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा । आद्येऽकर्मको द्वितीये सकर्मकः । श्लोकते । शुश्लोके ॥ **शकि** शङ्कायां । शङ्कते । शशङ्के ॥ **अकि** लक्षणे । अङ्कते । आनङ्के ॥ **ककि वकि श्वकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ तीकृ रघि लघि** गत्यर्थाः । कङ्कते । वङ्कते । श्वङ्कते । त्रङ्कते । ढौकते । डुढौके । त्रौकते । तुत्रौके । (सुब्धातुष्ठिवुष्वष्कतीनां सत्वनिषेधः) । ष्वष्कते । षष्वष्के । वस्कते । ववस्के । मस्कते । ममस्के । टेकते । टीकते । तेकते । तीकते । रङ्घते । लङ्घते ॥ **श्लाघृ** कत्थने । श्लाघते ॥ **पचि** व्यक्तीकरणे । पञ्चते । पपञ्चे ॥ **ऋज** गतिस्थानार्जनोपार्जनेषु । अर्जते । (नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते) आनृजे ॥ **ऋजिभृजी** भर्जने । ऋञ्जांचक्रे । भर्जते ॥ **एजृ भ्रेजृ भ्राजृ** दीप्तौ । एजते । एजांचक्रे । भ्रेजते । बिभ्रेजे । भ्राजते । बभ्राजे ॥ **वेष्ट** वेष्टने । वेष्टते । विवेष्टे ॥ **चेष्ट** चेष्टायाम् । चेष्टते । चिचेष्टे ॥ **स्फुट** विकसने । स्फोटते । पुस्फुटे ॥ **टुवेपृ** कम्पने । वेपते ॥ **कपि** चलने । कम्पते ॥ **भिक्ष** भिक्षायामलाभे लाभे च । भिक्षते । बिभिक्षे ॥ **दीक्ष** मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीक्षे ॥ **भाष** व्यक्तायां वाचि । भाषते । बभाषे ॥ **वर्ष** स्नेहने । वर्षते । ववर्षे ॥ **ईह** चेष्टायाम् । ईहते । ईहांचक्रे ॥ **गर्ह गल्ह** कुत्सायाम् । गर्हते । गल्हते ॥ **काशृ** दीप्तौ । काशते ॥ **ऊह** वितर्के । ऊहते । ऊहांचक्रे । कथम् 'अनुक्तमप्यूहति[1] पण्डितो जनः' इति । (अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम्) । अनुदात्तेतश्चक्षिङो[2] ङित्करणाज्ज्ञापकात् । तेन 'उदयति[3] यदि भानुः' 'स्फायन्निर्मोकसंधिः[4]' इत्या-

---

१ ऊहति वितर्कयति । २ अनुदात्तेत्त्वेनैव तङि सिद्धे ङित्करणं व्यर्थमिति भावः । ३ उदयतीति उत्पूर्वस्यायधातो रूपम् । ४ स्फायन्निति । स्फायी वृद्धौ इत्यनुदात्तेतो लटः शत्रादेशः ।

दिसिद्धमित्याहुः ॥ **अय** गतौ । अयते ॥ **उपसर्गस्यायतौ** ।८।२।१९। अयतावुपसर्गरेफस्य लत्वम् । प्लायते । पलायते ॥ **दयायासश्च** ।३।१।३७। एभ्य आम्लिटि । अयांचक्रे । अयिता । अयिष्यते । अयताम् । आयत । अयेत । अयिषीष्ट ॥ **विभाषेटः** ।८।३।७। इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् । आयिष्यत ॥ **द्युत** दीप्तौ । द्योतते ॥ **द्युतिस्वाप्योः संप्रसारणम्** ।७।४।६७। अभ्यासस्य । दिद्युते । द्योतिता । द्योतिष्यते । द्योतताम् । अद्योतत । द्योतेत । द्योतिषीष्ट ॥ **द्युद्भ्यो लुङि** ।१।३।९१। द्युतादिभ्यः परस्मैपदं वा लुङि । पुषादीत्यङ् । अद्युतत् । अद्योतिष्ट । अद्योतिष्यत । एवं **श्विता** वर्णे ॥ **ञिमिदा** स्नेहने ॥ **ञिष्विदा** स्नेहनमोचनयोः । मोहनयोरित्येके ॥ **रुच** दीप्तावभिप्रीतौ च ॥ **घुट** परिवर्तने ॥ **शुभ** दीप्तौ ॥ **क्षुभ** संचलने ॥ **णभ तुभ** हिंसायाम् ॥ **स्रंसु ध्वंसु भ्रंसु** अवस्रंसने ॥ **ध्वंसु** गतौ च ॥ **श्रम्भु** विश्वासे ॥ **वृतु** वर्तने । वर्तते । (ऋद्‌दुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन । ववृते । वर्तिता ॥ **वृद्भ्यः स्यसनोः** ।१।३।९२। वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्ये सनि च ॥ **न वृद्भ्यश्चतुर्भ्यः** ।७।२।५९। वृत् वृध् शृध् स्यन्दूभ्यः सादेरार्धधातुकस्येण्न तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । वर्तताम् । अवर्तत । वर्तेत । वर्तिषीष्ट । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत । एवं ॥ **वृधु** वृद्धौ ॥ **शृधु** शब्दकुत्सायाम् ॥ **स्यन्दू** प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोरिति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यान्न वृद्भ्य इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्देत । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङीति परस्मैपदपक्षेऽङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्य-

---

१ यद्यपीटः षीध्वमवयवत्वात्तस्य ततः परत्वं दुरुपपादं तथापि श्रुतिकृतानन्तर्यमात्रेण शास्त्रस्य प्रवृत्तिसामर्थ्याद्बोध्या । २ गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः ।

न्दिष्यत । अस्यन्त्स्यत ॥ **अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु** ।८।३।८२। एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा । अनुष्यन्दते । अनुस्यन्दते वा जलम् । अप्राणिषु[1] किम् । अनुस्यन्दते हस्ती ॥ **कृपू** सामर्थ्ये ॥ **कृपो रो लः** ।८।३।१८। कृपः उ इति छेदः । कृपे रेफस्य लः । कृपेर्ऋकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चक्लृपिषे । चक्लृप्से । इत्यादि स्यन्दिवत् ॥ **लुटि च कृपः** ।१।३।९३। लुटि स्यसनोश्च कृपेः[2] परस्मैपदं वा ॥ **तासि च[3] कृपः** ।७।२।६०। कृपेः परस्य तासेः सादेरार्धधातुकस्येण्न तङानयोरभावे । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट ॥ **लिङ्सिचावात्मनेपदेषु** ।१।२।११। इक्समीपाद्धलः परौ झलादी लिङात्मनेपदपरः सिचेत्येतौ कितौ स्तः । क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट । अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत । इति द्युतादयः ॥ **दद** दाने । ददते । ददे । ददाते । ददिरे । ददिता । ददिष्यते । ददताम् । अददत । ददेत । ददिषीष्ट । अददिष्ट । अददिष्यत ॥ **त्रपूष्** लज्जायाम् । त्रपते ॥ **तॄ[4]फलभजत्रपश्च** ।६।४।१२२। एषामत एत्वमभ्यासलोपश्च किति लिटि सेटि थलि च । त्रेपे । त्रपिता । त्रप्ता । त्रपिष्यते । त्रप्स्यते । त्रपताम् । अत्रपत । त्रपेत । त्रपिषीष्ट त्रप्सीष्ट । अत्रपिष्ट । अत्रप्त । अत्रपिष्यत । अत्रप्स्यत ॥ **घट** चेष्टायाम् । घटते । जघटे ॥ **व्यथ** भयसंचलनयोः ॥ **व्यथो लिटि** ।७।४।६८ व्यथेरभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषा[5]पवादः । विव्यथे ॥ **प्रथ** प्रख्याने । प्रथते । पप्रथे ॥

---

१ अप्राणिष्विति पर्युदासान्मत्स्योदके अनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव, प्राणिषु नेत्युक्तौ तु न स्यात् । २ एवं चात्र कृपेस्तस्यावृत्तिरवश्यं कर्तव्या । तथा च लुटि च कृप इत्यादि सौत्रनिर्देशोऽप्युपपद्यत इति भावः । ३ चकारात्सार्वधातुकं गृह्यते । ४ तरतेरकारस्य गुणशब्देन भावितत्वात्फलभजोर्वैरूप्यसंपादकादेशादित्वात्त्रपतेस्त्वेकहल्मध्यस्थत्वाभावादप्राप्ते विधिरयम् । ५ हलादिःशेषप्रक्रमणादिति भावः । एवं च उत्सर्गसदेशश्चापवाद इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटाद्युक्तो न संप्रसारण इति निषेधोऽत्र नापेक्षितः ।

प्रस विस्तारे । प्रसते ॥ **म्रद** मर्दने । म्रदते ॥ **स्खद** स्खदने । स्खदनं विद्रावणम् । स्खदते ॥ **क्रप** कृपायां गतौ च । क्रपते ॥ **ञित्वरा** संभ्रमे ॥ त्वरते ॥ **टुभ्राजृ टुभ्राशृ टुभ्लाशृ** दीप्तौ । भ्राजते ॥ **फणां च सप्तानाम्** ।६।४।१२५। फण, राजृ, भ्राजृ, भ्राशृ, भ्लाशृ, स्यमु, स्वन, एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । भ्रेजे । बभ्राजे । वा भ्राशेति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्लाशे । भ्लाश्यते । भ्लेशे ॥ **रम** क्रीडायाम् । रमते । रेमे । रन्ता ॥ **जभी जृभी** गात्रविनामे ॥ **रधिजभोरचि** ।७।१।६१। नुम् । जंभते । जजंभे । जृंभते । जजृंभे ॥

इत्यात्मनेपदप्रक्रिया ॥

श्रिञ् सेवायाम् । श्रयति । श्रयते । शिश्राय । शिश्रिये । श्रयितासि । श्रयितासे । श्रयिष्यति । श्रयिष्यते । श्रयतु । श्रयताम् । अश्रयत् । अश्रयत । श्रयेत् । श्रयेत । श्रीयात् । श्रयिषीष्ट । अशिश्रियत् । अशिश्रियत । अश्रयिष्यत् ॥ अश्रयिष्यत ॥ **भृञ्** भरणे । भरति । भरते । बभार । बभ्रतुः । बभ्रुः । बभर्थ । बभृम । बभ्रे । बभृषे । भर्तासि । भर्तासे । भरिष्यति । भरिष्यते । भरतु । भरताम् । अभरत् । अभरत । भरेत् । भरेत । भ्रियात् ॥ **उश्च** ।१।२।१२। ऋवर्णात्परौ झलादिलिङात्मनेपदपरः सिचेत्येतौ कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत्[1] ॥ **ह्रस्वादङ्गात्**[2] ।८।२।२७। सिचो लोपो झलि । अभृत । अभरिष्यत् । अभरिष्यत ॥ **हृञ्** हरणे । हरति । हरते । जहार । जह्रतुः । जह्रुः । जहर्थ । जह्रिव । जह्रिम । जह्रे ॥ जह्रिषे । हर्तासि । हर्तासे । हरिष्यति । हरिष्यते । **धृञ्** धारणे । धरति । धरते ॥ **णीञ्** प्रापणे । नयति । नयते ॥ **डुपचष्** पाके । पचति । पचते । पपाच । पेचिथ । पपक्थ । पेचे । पक्ता । पक्ष्यति । पक्ष्यते ॥ **भज** सेवायाम् । भजति । भजते । भेजे । भक्तासि । भक्तासे । भक्ष्यति । भक्ष्यते । भजतु । भजताम् । अभाक्षीत् । अभक्त । अभक्षाताम् ॥ **यज** देवपूजासङ्गतिकरणदानेषु । यजति ।

---

१ सिचि वृद्धिरिति वृद्धिः । २ केचित्त्विहाङ्गग्रहणाभावे अपाचिष्टाम् अलाविष्टामित्यादावप्यतिप्रसङ्गः स्यादित्याहुस्तदपरे न क्षमन्ते । संनिपातपरिभाषयापि परिहारसंभवादिति ।

यजते ॥ **लिट्यभ्यासस्योभयेषाम्** ।६।१।१७। वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥ **वचिस्वपियजादीनां किति** ।६।१।१५। वचिस्वप्योर्यजादीनां च संप्रसारणं किति ॥

यजिर्वपिर्वहिश्चैव वसिर्वेञ् व्येञ् च इत्यपि ।
ह्वेञवदी श्वयतिश्चैव यजाद्याः स्युरिमे नव ॥ १ ॥

ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । यक्ष्यते । यजतु । यजताम् । अयजत् । अयजत । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट ॥ **वह** प्रापणे । वहति । वहते । उवाह । ऊहतुः । ऊहुः । उवहिथ । 'झषस्तथोर्धोऽधः' । **ढो ढे लोपः** ।८।३।१३॥ **सहिवहोरोदवर्णस्य** ।६।३।११२। ढलोपे । उवोढ । ऊहे । वोढा । वक्ष्यति । वक्ष्यते । वहतु । वहताम् । उह्यात् । वक्षीष्ट । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवक्षाथाम् । अवोढ्वम् । अवक्षि । अवक्ष्वहि । अवक्ष्महि ॥ **डुवप्** बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । वपते । उवाप । ऊपे । वप्ता । वप्स्यति । वप्स्यते । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त ॥ **वेञ्** तन्तुसन्ताने । वयति । वयते ॥ **वेञो वयिः** ।२।४।४१। वा स्यात् लिटि । इकार उच्चारणार्थः । उवाय ॥ **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** ।६।१।१६। चात्किति संप्रसारणम् । इति यस्य प्राप्ते ॥ **लिटि वयो यः** ।६।१।३८। वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥ **वश्चास्यान्यतरस्यां किति** ।६।१।३९। वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवत्त्वेन ञित्वात् तङ् । ऊये । ऊवे । वयादेशाभावे ॥ **वेञः** ।६।१।४०। संप्रसारणं न लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । ववाते । वविरे । वाता । ऊयात् । वासीष्ट । अवासीत् । अवासिष्टाम् । अवासिषुः ॥ **व्येञ्** संवरणे । व्ययति । व्ययते ॥ **न व्यो लिटि** ।६।१।४६। आत्वम् । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसार-

णम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः ॥ **इडत्यर्तिव्ययतीनाम्** ।७।२।६६। अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् । विव्ययिथ । विव्यथुः । विव्य । विव्याय । विव्यय । विव्यिव । विव्यिम । विव्ये । व्याता । व्यास्यति । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ॥ **ह्वेञ्** स्पर्धायां शब्दे च । ह्वयति । ह्वयते ॥ **अभ्यस्तस्य च** ।६।१।३३। अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणम् । जुहाव । जुहुवे । ह्वाता । ह्वास्यति । ह्वास्यते ॥ **लिपि सिचि ह्वश्च** ।३।१।५३। च्लेरङ् ॥ **आत्मनेपदेष्वन्यतरस्याम्** ।३।१।५४। अह्वत् । अह्वताम् । अह्वत । अह्वास्त ॥ **राजृ** दीप्तौ । राजति । राजते । रराज । रेजतुः । रराजतुः । रेजुः । रराजुः । रेजे । रराजे ॥ **हिक्क** अव्यक्ते शब्दे । हिक्कति । हिक्कते ॥ **अञ्चु** गतौ पूजने च । अञ्चति । अञ्चते । अच इत्येके । अचीत्यपरे ॥ **टुयाचृ** याच्ञायाम् । याचति । याचते ॥ **बुधिर्** बोधने । बोधति । बोधते । अबुधत् । अबोधीत् । अबोधिष्ट ॥ **खनु** अवदारणे । खनति । खनते । चखान । चख्नतुः । चख्नुः । चख्ने । खायात् । खन्यात् ॥ **चीवृ** आदानसंवरणयोः । चीवति । चीवते ॥ **चायृ** पूजानिशामनयोः । चायति । चायते ॥ **व्यय** गतौ । व्ययति । व्ययते ॥ **दाश्ट** दाने । दाशति । दाशते ॥ **भेषृ** भये । गतावित्येके । भेषति । भेषते ॥ **अस** गतिदीप्त्यादानेषु । असति । असते । आस । आसे । अयं षान्तोऽपि ॥ **स्पश** बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते ॥ **लष** कान्तौ । लष्यति । लषति । लषते । लष्यते ॥ **चष** भक्षणे । चषति । चषते ॥ **झष** आदानसंवरणयोः । झषति । झषते ॥ **दासृ** दाने । दासति दासते ॥ **धावु** गतिशुद्ध्योः । धावति । धावते । इति भ्वादिः ॥

अथादादिगणः ॥ २ ॥

ऋतेरीयङ् ।३।१।२९। स्वार्थे ॥ **ऋतिः** सौत्रः । जुगुप्सायामिति बहवः ।

---

१ अत्र विकल्पेनात्वं ये विभाषेत्यनेनेति ज्ञेयम् । २ ऋतेरिति तान्तोयं धातुरिका निर्दिष्टो नत्विकारान्तः । 'वञ्चिलुञ्च्यृतश्च' इति निर्देशात् । केचित्त्विदन्तमाहुः । इदन्तत्वे तु 'एरनेकाच' इति यण् स्यात् ॥

कृपायां चेत्येके । ऋतीयते । ऋतीयांचक्रे । आयादयइति ईयङभावपक्षे शेषात्कर्तरीति परस्मैपदम् । आनर्त । अर्तिता । अर्तिष्यतीत्यादि ॥ **अद भक्षणे** ॥ **अदिप्रभृतिभ्यः शपः** ।२।४।७२। लुक् स्यात् । अत्ति । अत्तः । अदन्ति । अत्सि । अत्थः । अत्थ । अद्मि । अद्वः । अद्मः ॥ **लिट्यन्यतरस्याम्** ।२।४।४०। अदो घस्लृ स्यात् । जघास । उपधालोपः । घस्य चर्त्वे ॥ **शासिवसिघसीनां च** ।८।३।६०। इण्कुभ्यामेषां सस्य षः । जक्षतुः । जक्षुः । जघसिथ । आदतुः । आदुः । आदिथ । अत्ता । अत्स्यति । अत्तु । अत्तात् । अत्ताम् । अदन्तु ॥ **हुझल्भ्यो हेर्धिः** ।६।४।१०१। होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि । अत्तात् । अत्तम् । अत्त । अदानि । अदाव । अदाम ॥ **अदः सर्वेषाम्** ।७।३।१०४। अदः परस्यापृक्तस्य सार्वधातुकस्याट् स्यात् । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यात् । अद्यास्ताम् । अद्यासुः ॥ **लुङ्सनोर्घस्लृ** ।२।४।३७। अदः । अघसत् । आत्स्यत् ॥ **हन हिंसागत्योः** ॥ **अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति** ।६।४।३७। अनुनासिकान्तानामेषां लोपः । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः । घ्नन्ति । हंसि । हथः । हथ । हन्मि । हन्वः । हन्मः ॥ **वमोर्वा** ।८।४।२३। उपसर्गस्थान्निमित्ताद्धन्तेर्नस्य णः । प्रहण्मि । प्रहन्मि । प्रहण्वः । प्रहण्मः । प्रहन्मः । जघान । जघ्नतुः । जघ्नुः ॥ **अभ्यासाच्च** ।७।३।५५। हन्तेर्हस्य कुत्वं स्यात् । जघनिथ । जघन्थ । जघ्नथुः । जघ्न । जघान । जघन । जघ्निव । जघ्निम । हन्ता । हनिष्यति । हन्तु । हतात् । हताम् । घ्नन्तु ॥ **हन्तेर्जः** ।६।४।३५। हौ ॥ **असिद्धवदत्राभात्** ।६।४।२२। इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति जस्यासिद्धत्वान्न हेर्लुक् । जहि । हतात् । हतम् । हत । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहत् । अह-

१ अनुनासिकेति लुप्तषष्ठीकमसमस्तं सौत्रत्वाल्लुप्तविभक्तिकमित्यर्थः । वनतीतरेषां विशेषणम् ।

तम् । अहत । अहनम् । अहन्व । अहन्म । हन्यात् ॥ **आर्धधातुके ।२।४।६५।** इत्यधिकृत्य ॥ **हनो वध लिङि ।२।४।४२। लुङि च ।२।४।४३।** वध्यात् । वध्यास्ताम् । अवधीत् । अहनिष्यत् ॥ **यु** मिश्रणामिश्रणयोः ॥ **उतो वृद्धिर्लुकि हलि ।७।३।८९।** लुग्विषये उतो वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य[१] । यौति । युतः । युवन्ति । यौषि । युथः । युथ । यौमि । युवः । युमः । युयाव । युयुवतुः । युयुवुः । युयविथ । युयोथ । युयुवथुः । युयुव । युयाव । युयव । युयुविव । युयुविम । यविता । यविष्यति । यौतु । युतात् । अयौत् । अयुताम् । अयुवन् । युयात् । इह वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्नेति व्याख्यानात्[२] । युयाताम् । युयुः । यूयात् । यूयास्ताम् । यूयासुः । अयावीत् । अयविष्यत् ॥ **या** प्रापणे । याति । यातः । यान्ति । ययौ । याता । यास्यति । यातु । अयात् । अयाताम् । **लङः शाकटायनस्यैव ।३।४।१११।** आदन्ताल्लङो झेर्जुस्वा । अयुः । अयान् । यायात् । यायाताम् । यायुः । यायात् । यायास्ताम् । यायासुः । अयासीत् । अयास्यत् । एवं **वा** गतिगन्धनयोः ॥ **भा** दीप्तौ ॥ **ष्णा** शौचे । वान्यस्य संयोगादेरित्येत्वम् । स्नेयात् । स्नायात् ॥ **श्रा** पाके ॥ **द्रा** कुत्सायां गतौ ॥ **प्सा** भक्षणे ॥ **पा** रक्षणे ॥ **रा** दाने ॥ **ला** आदाने ॥ **दाप्** लवने ॥ **ख्या** प्रकथने । अयं सार्वधातुक एव प्रयोक्तव्यः ॥ **विद** ज्ञाने ॥ **विदो लटो वा ।३।४।८३।** वेत्तेर्लटः[३] परस्मैपदानां णलादयो वा । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे । वेत्ति । वित्तः । विदन्ति ॥ **उषविदजागृभ्योऽन्यतरस्याम् ।३।१।३८।** एभ्यो लिट्याम् वा । विदेरदन्तत्वप्रतिज्ञानादामि न गुणः । विदांचकार । विवेद । वेदिता । वेदिष्यति ॥ **विदांकुर्वन्त्वित्यन्यतरस्याम् ।३।१।४१।** वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न[४] विवक्षिते इति-

---

१ 'नाभ्यस्तस्याचि पिति' इत्यनुवृत्तेराह—नत्वभ्यस्तस्येति । २ विशेषविहितेन ङित्वेन पित्वस्य बाधात् । ३ वेत्तेरिति पञ्चमीयं नतु षष्ठी । तेन विद्यतिविन्दत्योर्व्यवहितपरस्य लटोऽभावान्नैते आदेशास्तदाह—वेत्तेरिति । ४ न विवक्षिते इति तयोर्नान्तरीयकतया उच्चार्यमाणत्वादिति भावः ।

शब्दात् ॥ **तनादिकृञ्भ्य उः** ।३।१।७९। शपोऽपवादः । विदांकरोतु ॥ **अत उत्सार्वधातुके** ।६।४।११०। उप्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति । विदांकुरुतात् । विदांकुरुताम् । विदांकुर्वन्तु । विदांकुरु । विदांकरवाणि । वेत्तु । अवेत् । अवित्ताम् । अविदुः ॥ **दश्च** ।८।२।७५। धातोः पदान्तस्य दस्य सिपि रुर्वा । अवेः । अवेत् । विद्यात् । विद्याताम् । विद्युः । विद्यात् । विद्यास्ताम् । विद्यासुः । अवेदिष्यत् ॥ **अस** भुवि । अस्ति ॥ **श्नसोरल्लोपः** ।६।४।१११। श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति । स्तः । सन्ति । असि । स्थः । स्थ । अस्मि । स्वः । स्मः ॥ **अस्तेर्भूः** ।२।४।५२। आर्धधातुके । बभूव । भविता । भविष्यति । अस्तु । स्तात् । स्ताम् । सन्तु ॥ **घ्वसोरेद्धावभ्यासलोपश्च** ।६।४।११९। घोरस्तेश्चैत्वं[1] हौ अभ्यासलोपश्च । आभीयत्वाद्धेर्धिः । एधि । स्तात् । स्तम् । स्त । असानि । असाव । असाम । आसीत् । आस्ताम्[2] । आसन् । स्यात् । स्याताम् । स्युः । भूयात् । अभूत् । अभविष्यत् ॥ **उपसर्गप्रादुर्भ्यामस्तिर्यच्परः**[3] ।८।३।८७। उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य षो यकारेऽचि च परे । निःष्यात् । प्रादुःष्यात् । निःषन्ति । प्रादुःषन्ति । यच्परे किम् । अभिस्तः ॥ रु शब्दे ॥ **तुरुस्तुशम्यमः सार्वधातुके** ।७।३।९५। एभ्यः सार्वधातुकस्य हलादेस्तिङ ईड्वा । नाभ्यस्तस्येत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम्[4] । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि । रूयात् । विध्यादौ तु रुयात् । रुवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुः गतिवृद्धिहिंसासु । तवीति । तौति । तुवीतः । तुतः । तुवन्ति । तुताव । तोता । तोष्यति ॥ **णु** स्तुतौ । नौति । नुनाव । नविता ॥ **टुक्षु** शब्दे । क्षौति ।

---

१ एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम् । २ आस्तामित्यत्र श्नसोरित्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् भवति । ३ प्रादुसिति सान्तमव्ययम् । प्रादुषिति प्राचां षान्तपाठः प्रामादिकः । ४ एभ्यः परस्य पितः सार्वधातुकस्येति प्राचो व्याख्यानं प्रामादिकम् ।

चुक्षाव । क्षविता ॥ **क्ष्णु** तेजने । क्ष्णौति । क्ष्णविता । अक्ष्णावीत् ॥ **ष्णु** प्रस्रवणे । स्नौति । सुष्णाव । स्नविता ॥ **षु** प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सौति । सुतः । सुषाव । सोता । असौषीत् ॥ **कु** शब्दे । कौति । चुकाव । कोता ॥ **इण्** गतौ । एति । इतः ॥ **इणो यण्** ।६।४।८१। अजादौ प्रत्यये । इयङोऽपवादः । यन्ति ॥ **अभ्यासस्यासवर्णे** ।६।४।७८। अभ्यासस्येवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । इयाय ॥ **दीर्घ इणः किति** ।७।४।६९। इणोऽभ्यासस्य दीर्घः किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । एष्यति । एतु । ऐत् । ऐताम् । आयन् । इयात् । ईयात् । **एतेर्लिङि** ।३।४।२४। उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । (उभयत आश्रयणे नान्तादिवत्) ॥ **अन्तादिवच्च** ।६।१।८५। योयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्स्यात्[1] । अभीयात् । अणः किम् । समेयात् ॥ **इणो गा लुङि** ।२।४।५१। गाति स्थेति सिचो लुक् । अगात् । अगाताम् । अगुः । ऐष्यत् ॥ **इक्** स्मरणे । अयमधिपूर्व एव । 'अधीगर्थदयेशां कर्मणि' इति लिङ्गात् । (इण्वदिक इति वक्तव्यम्) । अधियन्ति । अध्यगात् । केचित्त्वार्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथा च भट्टिः । ससीतयो राघवयोरधीयन्निति[2] ॥ **वी** गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वीहि । अवेत् । अविताम् । अवियन् । अटि सति अनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्र ईकारोपि धात्वन्तरं प्रश्लिष्यते । एति । ईतः । इयन्ति । इयात् । ऐषीत् ॥ **वच** परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये । झिपर इत्यपरे । वक्तु । वग्धि । वच्यात् । उच्यात् ॥ **अस्यतिवक्तिख्यातिभ्योऽङ्** ।३।१।५२। च्लेः ॥ **वच उम्**

---

१ स्थानिवत्सूत्रेणैव गतार्थमिदम् । न चाल्विध्यर्थमिदमस्त्विति शङ्क्यम् । अस्याप्यल्विधावनिष्टत्वात् । अन्यथा अयजे इन्द्रमित्यत्र सवर्णदीर्घापत्तेः । २ राघवयोरित्यत्र 'अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी ।

।७।४।२०। अङि । अवोचत् । अवक्ष्यत् ॥ **मृजू** शुद्धौ ॥ **मृजेर्वृद्धिः** ।७।२।११४। इको धातुप्रत्यये परे । मार्ष्टि । मृष्टः । क्ङित्यजादौ वेष्यते । मृजन्ति । मार्जन्ति । ममार्ज । ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता । मार्ष्टा । मार्ष्टु । मृड्ढि । अमार्ट् । अमार्ड् । अमार्जीत् । अमार्क्ष्यत् । अमार्जिष्यत् ॥ **रुदिर्** अश्रुविमोचने ॥ **रुदादिभ्यः सार्वधातुके** ।७।२।७६। रुद् स्वप् श्वस् अन् जक्ष् एभ्यो वलादेः सार्वधातुकस्येट् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥ **रुदश्च पञ्चभ्यः** ।१।३।९८। हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् ॥ **अड् गार्ग्यगालवयोः** ७।३।९९। अरोदीत् । अरोदत् । अरुदिताम् । अरुदन् । अरोदीः । अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट् । (असिद्धं बहिरङ्गमन्तरङ्गे) रुद्यात् । अरुदत् । अरोदीत् । अरोदिष्यत् ॥ **ञिष्वप्** शये । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुष्वपिथ । सुष्वप्थ ॥ **सुविनिर्दुर्भ्यः सुपिसूतिसमाः** ।८।३।८८। एभ्यः सुप्यादेः सस्य षः किति लिटि । परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । (पूर्वत्रासिद्धीयमद्विर्वचने) । सुषुषुपतुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यासिद्धत्वात् । ततः पूर्वं हलादिः शेषः । नित्यत्वाच्च । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । स्वप्ता । अस्वपीत् । अस्वप । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वप्स्यत् ॥ **श्वस** प्राणने । श्वसिति । श्वसितः । शश्वास । श्वसिता । श्वसिष्यति । श्वसितु । अश्वसीत् । अश्वसत् । अश्वसिताम् । अश्वसन् । श्वस्यात् । ह्यन्तेति वृद्धिर्न । अश्वसीत् ॥ **अन** च । अनिति । आन । अनिता । आनीत् । आनत् ॥ **अनितेः** ।८।४।१९। उपसर्गस्थान्निमित्तात् परस्यानिते-

---

१ मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । व्रश्चेति षत्वमिति सिद्धान्तकौमुद्याम् । २ धित्वं नेति । सकृद्गताविति न्यायात् हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थ इत्यादि प्रागुक्तसमाधानाच्चेति भावः । ३ हलादिपित्सार्वधातुकापृक्तापेक्षत्वाच्च बहिरङ्गत्वमडीटोः । ४ परस्परापेक्षया व्याप्यनिमित्तकमन्तरङ्गं व्यापकनिमित्तं च बहिरङ्गमित्युत्सर्गः । विलम्बोपस्थितिकत्वं च बहिरङ्गस्यासिद्धत्वे बीजम् ।

र्नस्य णः । प्राणिति ॥ **जक्ष** भक्षहसनयोः । जक्षिति । जक्षितः ॥ **अदभ्यस्तात्** ।७।१।४। झस्य । अन्तापवादः । जक्षति । अजक्षीत् । अजक्षत् । अजक्षिताम् । सिजभ्यस्तेति जुस् । अजक्षुः ॥ **जागृ** निद्राक्षये । जागर्ति । जागृतः । जाग्रति । जागरांचकार । जजागार ॥ **जाग्रोऽविचिण्णल्ङित्सु** ।७।३।८५। जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । जजागरुः । जागरिता । अजागः । अजागृताम् ॥ **जुसि च** ।७।३।८३। अजादौ जुसि इगन्ताङ्गस्य गुणः । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु । जागर्यात् । जागर्यास्ताम् । जागर्यासुः । अजागरीत् ॥ **दरिद्रा** दुर्गतौ । दरिद्राति ॥ **इद्दरिद्रस्य** ।६।४।११४। हलादौ क्ङिति सार्वधातुके । दरिद्रितः । **श्नाभ्यस्तयोरातः** ।६।४।११२। लोपः क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । 'आत औ णलः' इत्यत्र ओ इत्येव सिद्धे औविधानं दरिद्रातेरालोपे कृते श्रवणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । (दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः) (लुङि वा) । (सनि ण्वुलि ल्युटि च न) । दरिद्रिता । अदरिद्रीत् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदरिद्रीत् । इट्सकौ । अदरिद्रासीत् ॥ **चकासृ** दीप्तौ । चकास्ति । चकास्तः । चकासति । चकासांचकार । चकासिता । चकास्तु । चकाधि ॥ **तिप्यनस्तेः** ।८।२।७३। पदान्तस्य सस्य दः[1] । अचकात् । अचकाद् । अचकास्ताम् । अचकासुः ॥ **सिपि धातोरुर्वा** ।८।२।७४। पदान्तस्य सस्य । पक्षे दः[2] । अचकाः । अचकात् ॥ **शासु** अनुशिष्टौ । शास्ति ॥ **शास इदङ्हलोः** ।६।४।३४। शास उपधाया इत्स्यादङि[3] हलादौ क्ङिति च । शिष्टः । शासति । शशास । शशासतुः । शास्तु । शिष्टात् । शिष्टाम् । शासतु ॥ **शा हौ** ।६।४।३५। शास्तेः । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् ॥

---

१ विशब्देन वादिप्रत्ययो गृह्यते । इकारस्तूच्चारणार्थ इति वदतां मते क्वसावपि न भवति । २ दः स्यात्तिपि नत्वस्तेः । ३ अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह । आशास्ते ।

सर्तिशास्त्यर्तिभ्यश्च ।३।१।५६। एभ्यश्च्लेरङ् कर्तृलुङि । अशिषत् । अशासिष्यत् ॥

॥ इति परस्मैपदम् ॥

शीङ् स्वप्ने ॥ **शीङः सार्वधातुके गुणः** ।७।४।२१। शेते । शयाते ॥ **शीङो रुट्** ।७।१।६। झादेशस्यातः । शेरते । शेषे । शयाथे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । शयिषीष्ट । अशयिष्ट । अशयिष्यत ॥ **इङ्** अध्ययने इङिकावध्युपसर्गतो न व्यभिचरतः । अधीते । अधीयाते । अधीयते ॥ **गाङ् लिटि** ।२।४।४९। इङः । अधिजगे । अध्येता । अध्येष्यते । अधीताम् । अधीष्व । अधीयाथाम् । अधीध्वम् । अध्ययै । अध्ययावहै । अध्ययामहै । अध्यैत । अध्यैध्वम् । अध्यैयि । अध्यैवहि । अध्यैमहि । अधीयीत । अधीयीयाताम् । अधीयीरन् । अध्येषीष्ट ॥ **विभाषा लुङ्लृङोः** ।२।४।५०। इङो गाङ् ॥ **गाङ्कुटादिभ्योऽञ्णिन्ङित्** ।१।२।१। गाङादेशात्कुटादिभ्यश्चाञ्णितः प्रत्यया ङितः[1] स्युः ॥ **घुमास्थागापाजहातिसां हलि** ।६।४।६६। एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट[2] । अध्यैष्ट । अध्यगीष्यत ॥ **ईर** गतौ कम्पने च । ईर्ते । ईरांचक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ॥ **ईड** स्तुतौ । ईट्टे ॥ **ईशः से** ।७।१।७७। **ईडजनोर्ध्वे च** ।७।२।७८। ईशीड्जनां सेध्वेशब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागो वैचित्र्यार्थः[3] । ईडिषे । ईडिध्वे । एकदेशविकृतस्यानन्यत्वात् । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् ॥ **ईश** ऐश्वर्ये । ईशिषे । ईशिध्वे ॥ **आस** उपवेशने । आस्ते । दयायासश्चेत्याम् । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट ॥ **आङः शासु** इच्छायाम् । आशास्ते । आशासाते ॥ **वस** आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता ॥ **णिसि** चुम्बने

---

१ इह गाङ् गतावित्यस्य न ग्रहणम् । तङर्थतया ङकारानुबन्धस्य चरितार्थत्वात् । आदेशङकारस्त्वचरितार्थः । स्थानिवद्भावेनैव तङः सिद्धत्वादत आह । गाङादेशादिति । २ सिचो ङित्वादीत्वम् । ३ वैचित्र्यार्थं इति ध्वे इत्यस्य पूर्वत्रापकर्षः सेइत्यस्योत्तरत्रानुवृत्तिरित्येवं विचित्रबोधार्थं इत्यर्थः ।

निंस्ते ॥ **णिजि शुद्धौ** । निङ्क्ते । निङ्क्षे । निञ्जिता[१] ॥ **वृजी वर्जने** । वृक्ते । वृजाते । इदिदित्यन्ये । वृङ्क्ते ॥ **पृची संपर्चने** । पृक्ते ॥ **षूङ् प्राणिगर्भविमोचने** । सूते । सुषुवे । सुषुविषे । सोता । सविता । सुवै । सविषीष्ट । असविष्ट । असोष्ट ॥ **चक्षिङ् व्यक्तायां वाचि** । अयं दर्शनेपि । इकारोऽनुदात्तो युजर्थः । नुम्तु न । अन्त्य इदिति व्याख्यानात् । चष्टे । चक्षाते । आर्धधातुके ॥ **चक्षिङः ख्याञ्** ।२।४।५४। **वा लिटि** ।२।४।५५। अत्र भाष्ये खशादिरयमादेशः । असिद्धकाण्डे शस्य यो वेति स्थितम् । ञित्वात्पदद्वयम् । चख्यौ । चख्ये । चक्शौ । चक्शे । चचक्षे । ख्याता । क्शाता । ख्यास्यति । ख्यास्यते । क्शास्यति । क्शास्यते । चष्टाम् । अचष्ट । चक्षीत । ख्यायात् । ख्येयात् । क्शायाम् । क्शेयात् । अस्यतिवक्तीत्यङ् । अख्यत । अख्यत् । अक्शासीत् । अक्शास्त । वर्जने क्शाञ् नेष्टः । समचक्षिष्टेत्यादि ॥ **द्विष अप्रीतौ** । द्वेष्टि । द्विष्टे । द्वेक्ष्यति । द्विड्ढि । द्वेषै । अद्वेट् ॥ **द्विषश्च**[२] ।३।४।११२। लङो झेर्जुस्वा । अद्विषुः । अद्विषन् । अद्विक्षत् ॥ **दुह प्रपूरणे** । 'दादेर्धातोर्घः' इति हस्य घः । दोग्धि । दुग्धः । दुहन्ति । धोक्षि । दुग्धे । दुहाते । दुहते । धुक्षे । दुहाथे । धुग्ध्वे । दुह्वहे । दुह्महे । दुदोह । दुदुहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्धु । दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धि । दुग्धात् । दुग्धम् । दुग्ध । दोहानि । दुग्धाम् । दुहाताम् । दुहताम् । धुक्ष्व । दुहाथाम् । धुग्ध्वम् । दोहै । दोहावहै । दोहामहै । अधोक् । अदुग्धाम् । अदुहन् । अदोहम् । अदुग्ध । अदुहाताम् । अदुहत । अधुग्ध्वम् । दुह्यात ॥ दुहीत । धुक्षीष्ट । अधुक्षत् ॥ **लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये** ।७।३।७३। एषां क्सस्य लुग्वा दन्त्ये तङि । अधुक्षत । अदुग्ध ॥ **क्सस्याचि** ।७।३।७२। अजादौ तङि क्सस्य लोपः । अधुक्षाताम् । अधुक्षन्त । अधुक्षथाः । अधुग्धाः । अधुक्षाथाम् । अधुक्षध्वम् । अधुग्ध्वम् । अधुक्षि । अधुक्षावहि । अदुह्वहि । अधुक्षामहि । अधोक्ष्यत् । अधोक्ष्यत ॥ एवं **दिह उपचये** । उपचयो वृद्धिः ॥ **लिह आस्वादने** । लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिहाते । लिहते । लिक्षे ।

---

१ अनिट्केषु णिजिर् इति जौहोत्यादिकस्य ग्रहणादयं सेट् । २ अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः ।

लिहाथे । लीढ्वे । लेढु । लीढात् । लीढाम् । लिहन्तु । लीढि । लेहानि । लीढाम् । अलेट् । अलीढाम् ॥ **ब्रूञ्** व्यक्तायां वाचि ॥ **ब्रुवः पञ्चानामादित आहो ब्रुवः** ।३।४।८४। ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आह । आहतुः । आहुः ॥ **आहस्थः** ।८।२।३५। झलि । चर्त्वम् । आत्थ । आहथुः ॥ **ब्रुव ईट्** ।७।३।९३। ब्रुवो हलादेः पित ईट् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । ब्रुवाते । ब्रुवते ॥ **ब्रुवो वचिः** ।२।४।५३। आर्धधातुके । उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । वक्ष्यति । वक्ष्यते । ब्रवीतु । ब्रूतात् । ब्रूताम् । ब्रूहि । ब्रवाणि । ब्रूताम् । ब्रवै । अब्रवीत् । अब्रूत । ब्रूयात् । ब्रुवीत । उच्यात् । वक्षीष्ट । अवोचत् । अवक्ष्यत् । चर्करीतं च । चर्करीतमिति यङ्लुगन्तमदादौ बोध्यम् ॥ **ऊर्णुञ्** आच्छादने ॥ **ऊर्णोतेर्विभाषा** ।७।३।९०। वृद्धिर्वा हलादौ पिति सार्वधातुके । ऊर्णौति । ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । ऊर्णुवाते । ऊर्णुवते । (ऊर्णोतेराम् नेति वाच्यम्)[1] ॥ **नन्द्राः संयोगादयः** ।६।१।३। अचः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम्[2] । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥ **विभाषोर्णोः** ।१।२।३। इडादिप्रत्ययो ङिद्वत् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णविता । ऊर्णुविता । ऊर्णौतु । ऊर्णवानि । ऊर्णवै ॥ **गुणोऽपृक्ते** ।१।३।९१। ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके । और्णोत् । और्णोः । और्णुतम् । ऊर्णुयात् । ऊर्णुयाताम् । ऊर्णूयात् । ऊर्णूयास्ताम् । ऊर्णुविषीष्ट । ऊर्णविषीष्ट । और्णुवीत् ॥ **ऊर्णोतेर्विभाषा** ।७।१।६। इडादौ परस्मैपदपरे सिचि वृद्धिः । पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णवीत् । और्णविष्टाम् ॥ **इत्यदादयः** ॥

अथ जुहोत्यादिगणः ॥ ३ ॥

हु दानादनयोः[3] ॥ **जुहोत्यादिभ्यः श्लुः** ।२।४।७५। शपः **श्लौ** ।६।१।१०।

---

१ ऊर्णोतेर्णुवद्भावो वाच्यः इति वक्ष्यमाणस्यामभावोऽपि फलमिति भावः । २ उपदेशे नकार एव । णत्वं तु 'रषाभ्याम्' इत्यनेनेति भावः । णत्वस्यासिद्धतया नुबुद्ध्यैव द्वित्वकरणात् । यद्बुद्ध्या शास्त्रप्रवृत्तिस्तद्द्वितीयप्रयोगस्यैव साधुत्वान्वाख्यानान्नोत्तरखण्डे णश्रवणम् । ३ यद्यपि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनमेव दानं तथापीह प्रयोगमनुसृत्य हविर्द्रव्यस्याग्न्यादौ प्रक्षेप एव दानं ज्ञेयम् ।

धातोर्द्वे स्तः । जुहोति । जुहुतः । हुश्नुवोरिति यण् । जुह्वति ॥ **भीह्रीभृहुवां श्लुवच्च** ।३।१।३९। एभ्यो लिट्याम् वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । जुहुताम् । जुह्वतु । जुहुधि । जुहवानि । अजुहोत् । अजुहुताम् । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । अहोष्यत् ॥ **ञिभी भये** । बिभेति ॥ **भियोऽन्यतरस्याम्** ।६।४।११५। इकारो वा स्याद्धलादौ सार्वधातुके क्ङिति । बिभीतः । बिभितः । बिभ्यति । बिभयांचकार । बिभाय । भेता । भेष्यति । बिभेतु । बिभीतात् । बिभीताम् । अबिभेत् । बिभीयात् । भीयात् । अभैषीत् । अभेष्यत् ॥ **ह्री लज्जायाम्** । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय । ह्रेता । ह्रेष्यति । जिह्रेतु । अजिह्रेत् । जिह्रीयात् । ह्रीयात् । अह्रैषीत् । अह्रेष्यत् ॥ **पॄ पालनपूरणयोः** ॥ **अर्तिपिपर्त्योश्च** ।७।४।७७। अभ्यासस्य इत्स्यात् श्लौ । पिपर्ति ॥ **उदोष्ठ्यपूर्वस्य** ।७।१।१०२। अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उः ॥ **हलि च** ।८।२।७७। रेफवान्तस्य धातोरुपधाया इको दीर्घो हलि । पिपूर्तः । पिपुरति । पपार ॥ **शॄदॄप्रां ह्रस्वो वा** ।७।४।१२। किति लिटि । पप्रतुः । पप्रुः ॥ **ऋच्छत्यॄताम्** ।७।४।११। तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणो लिटि । पपरतुः । पपरुः ॥ **वृतो वा** ।७।२।३८। वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । परिता । परीता । परिष्यति । परीष्यति । पिपर्तु । पिपुरतु । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पिपूर्युः । पूर्यात् । अपारीत् ॥ **सिचि च परस्मैपदेषु** ।७।२।४०। अत्र वृत इटो न दीर्घः । अपारिष्टाम् । अपरिष्यत् । अपरीष्यत् ॥ **ओहाक् त्यागे** । जहाति ॥ **जहातेश्च** ।६।४।११६। इकारो वा स्याद्धलादौ क्ङिति । जहितः ॥ **ईहल्यघोः** ।६।४।११३। श्नाभ्यस्तयोरात ईत्स्यात्सार्वधातुके क्ङिति हलि । जहीतः । जहति । जहौ । हाता । हास्यति । जहातु । जहितात् । जहीतात् ॥ **आ च हौ** ।६।४।११७। जहातेराच्चादिदीतौ स्तः ।

---

१ केचिदत्र हलादौ क्ङितीत्येतन्नातीवोपयुज्यते । इत्वविधानस्य बिभित इत्यादौ चरितार्थत्वात् । बिभ्यति बिभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः ।

जहाहि । जहिहि । जहीहि । अजहात्। अजहुः ॥ **लोपो यि** ।६।४।११९। जहातेरालोपो यादौ सार्वधातुके । जह्यात् । एर्लिङीति एत्वम् । हेयात् । अहासीत् । अहासत् ॥ **ऋ** गतौ । ईयर्ति । इयृतः । ईयूरति । आर । आरतुः । आरुः । इडत्त्यर्तीति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयर्तु । इयराणि । ऐयेः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । आरिष्यत् ॥ **माङ्** माने । शब्दे च ॥ **भृञामित्** ।७।४।७६। भृञ् माङ् ओहाङ् एषामभ्याससेत्स्याच्छ्लौ । मिमीते । मिमाते । श्नाभ्यस्तेति आतो लोपः । मिमते । ममे । माता । मास्यते । मिमीताम् । अमिमीत । मिमीत । मासीष्ट । अमास्त । अमास्यत ॥ **ओहाङ्** गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । जिहीताम् । अजिहीत । जिहीत । हासीष्ट । अहास्त । अहास्यत ॥ **डुभृञ्** धारणपोषणयोः । बिभर्ति । बिभृतः । बिभ्रति । बिभृते । बिभ्राते । बिभ्रते । बिभरांचकार । बभार । बभर्थ । बभृव । बिभरांचक्रे । बभ्रे । भर्ता । भरिष्यति । भरिष्यते । बिभर्तु । बिभराणि । बिभृताम् । अबिभः । अबिभरुः । अबिभृत । बिभ्रीत । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत । अभरिष्यत् । अभरिष्यत ॥ **डुदाञ्** दाने । ददाति । दत्तः । ददति । दत्ते । ददाते । ददते । ददौ । ददे । दाता । दास्यति । दास्यते । ददातु । देहि । दत्ताम् । अददात् । अदत्त । दद्यात् । ददीत । देयात् । दासीष्ट । अदात् । अदाताम् । अदुः ॥ **स्थाघ्वोरिच्च** ।१।२।२७। अनयोरिदन्तादेशः सिच्च किदात्मनेपदेषु । अदित । अदास्यत् । अदास्यत ॥ **डुधाञ्** धारणपोषणयोः ॥ **दधस्तथोश्च** ।८।२।३८। द्विरुक्तस्य

---

१ अभ्यासस्येयङ् अभ्यासादुत्तरस्य तु गुणः । २ अदभ्यस्तादित्यत् । ३ अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । सार्वधातुकेति ऋकारस्य गुणः । अभ्यासस्यासवर्णे इति इयङ् । इतश्चेतीकारलोपः । हल्ङ्याबिति तलोपः । रेफस्य विसर्गः । आडजादीनाम् आटश्चेति वृद्धिः । ४ गुणोर्तीति गुणः । ५ सर्तिशास्त्यर्तीत्यङि ऋदृशोऽङीति गुणः । ६ दध इति कृतद्विर्वचनाभ्यासकार्यो धात्रेव गृह्यते न तु दध धारणे इत्ययमिति व्याचष्टे द्विरुक्तस्येति ।

झषन्तस्य धाञो बशो भष् तथयोः स्ध्वोश्च परतः । धत्तः । दधति । दधासि । धत्थः । धत्ते । धत्से । धध्वे । धेहि ॥ **णिजिर्** शौचपोषणयोः ॥ **निजां त्रयाणां गुणः श्लौ** ।७।४।६५। निज्विज्विषामभ्यासस्य गुणः स्याच्छ्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज । निनिजे । नेक्ता । नेक्ष्यति । नेक्ष्यते । नेनेक्तु । नेनिग्धि ॥ **नाभ्यस्तस्याचि पिति सार्वधातुके** ।७।३।८७। लघूपधगुणो न । नेनिजानि । नेनिक्ताम् । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात् । नेनिजीत । निज्यात् । निक्षीष्ट । अनिजत् । अनैक्षीत् । अनिक्त । अनेक्ष्यत् । अनेक्ष्यत । एवं ॥ **विचिर्** पृथग्भावे ॥ **विष्लृ** व्याप्तौ ॥ इति जुहोत्यादयः ॥

अथ दिवादिगणः ॥ ४ ॥

दिवु[1] क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ॥ **दिवादिभ्यः श्यन्** ।३।१।६९। कर्तरि सार्वधातुके । शपोऽपवादः । हलि चेति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् । एवं ॥ **षिवु** तन्तुसन्ताने ॥ **सिवादीनां**[2] **वाड्व्यवायेऽपि** ।८।३।७१। परिनिविभ्यः परेषामेषां सस्य षः । पर्यषीव्यत् । पर्यसीव्यत् ॥ **नृती** गात्रविक्षेपे । नृत्यति । ननर्त । नर्तिता ॥ **सेऽसिचि कृतचृतच्छृदतृदनृतः** ।७।२।५७। एभ्यः सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा । नर्तिष्यति । नर्त्स्यति । नृत्यात् । अनर्तीत् ॥ **त्रसी** उद्वेगे । वाभ्राशेति श्यन्वा । त्रस्यति । त्रसति । तत्रास ॥ **वा**[3] **जॄभ्रमुत्रसाम्** ।६।४।१२४। एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा । त्रेसतुः । तत्रसतुः । त्रेसिथ । तत्रसिथ । त्रसिता ॥ **शो** तनूकरणे ॥ **ओतः श्यनि** ।७।३।७१। लोपः श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः ।

---

१ उदित्करणं क्त्वायामिड्विकल्पार्थं निष्ठायामनिडर्थं च । २ सिवुसहसुट्स्तुस्वञ्जः सिवादयः । ३ अप्राप्तविभाषेयम् ।

शशुः । शाता । शास्यति । अशात् । अशाताम् । इट्सकौ । अशासीत् । अशासिष्टाम् ॥ **छो** छेदने । छ्यति ॥ **षो** अन्तकर्मणि । स्यति । ससौ । सेयात् ॥ **दो** अवखण्डने । द्यति । ददौ । देयात् । अदात् ॥ **व्यध** ताडने । विध्यति[1] । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् ॥ **पुष** पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादीत्यङ् । आपरस्मैपदात् । अपुषत् ॥ **शुष** शोषणे । शुष्यति । शुशोष । अशुषत् ॥ **णश** अदर्शने । नश्यति । ननाश । नेशतुः ॥ **रधादिभ्यश्च** ।७।२।४५। रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् । नेशिथ ॥ **मस्जिनशोर्झलि** ।७।१।६०। नुम् स्यात् । ननंष्ठ । नेशिव । नेश्व । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥ **नशेः षान्तस्य** ।८।४।३६। णत्वं न । प्रनंष्टा । अन्तेर्ग्रहणं[2] भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति ॥ **रध** हिंसासंराध्योः ॥ **रधिजभोरचि** ।७।१।६१। नुम् । ररन्ध । ररन्धतुः । ररन्धिथ । ररद्ध । ररन्धिव । ररन्ध्व ॥ **नेट्यलिटि रधेः** ।७।१।६२। लिड्वर्जे इटि रधेर्नुम्न । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदितामिति नलोपः । अरधत् ॥ **तृप** प्रीणने । तृप्यति । ततर्प । ततर्प्थ । ततर्पिथ । तर्पिता । तर्प्ता । त्रप्ता । (स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः) । अतर्पीत् । अत्राप्सीत् । अतार्प्सीत् । अतृपत् ॥ **दृप** हर्षमोहनयोः । दृप्यति । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता ॥ **द्रुह** जिघांसायाम् । द्रुह्यति । वा द्रुहेति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । अद्रुहत् ॥ **मुह** वैचित्त्ये । वैचित्त्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोहिता । मोग्धा । मोढा । मोहिष्यति । मोक्ष्यति । अमुहत् ॥ **ष्णुह** उद्गिरणे । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहि-

---

१ श्यनः सार्वधातुकमपिदिति ङित्वे ग्रहिज्येति संप्रसारणम् । २ षस्येत्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयति भूतपूर्वेति ।

ष्यति । स्नोक्ष्यति । अस्नुहत् ॥ **ष्णिह** प्रीतौ । स्निह्यति । सिष्णेह । स्नेहिता । स्नेग्धा । स्नेढा । अस्निहत् ॥ **तुष** तुष्टौ । तुष्यति [१]॥ **दुष** वैकृत्ये । दुष्यति ॥ **श्लिष** आलिङ्गने । श्लिष्यति ॥ **श्लिष आलिङ्गने** ।३।१।४६। च्लेः क्सः । अश्लिक्षत् कन्यां देवदत्तः । आलिङ्गने किम् । समश्लिषज्जतु काष्ठम् । प्रत्यासत्ताविह श्लिषिः ॥ **क्रुध** क्रोधे । क्रुध्यति ॥ **क्षुध** बुभुक्षायाम् । क्षुध्यति ॥ **शुध** शौचे । शुध्यति ॥ **षिधु** संराद्धौ । सिध्यति ॥ **शमु** उपशमे ॥ **शमामष्टानां दीर्घः श्यनि** ।७।३।७४। शम् तम् दम् श्रम् भ्रम् क्षम् क्लम् मदामचो दीर्घः । प्रणिशाम्यति । शेमतुः । शेमुः । शेमिथ । शमिता । अशमत् ॥ **तमु** काङ्क्षायाम् । ताम्यति । तमिता । अतमत् ॥ **दमु** उपशमे । दाम्यति । दमिता । अदमत् ॥ **श्रमु** तपसि खेदे च । श्राम्यति । अश्रमत् ॥ **भ्रमु** अनवस्थाने । वाभ्राशेति श्यन्वा । भ्राम्यति । भ्रामति । भ्रेमतुः । बभ्रमतुः । अभ्रमत् ॥ **क्षमू** सहने । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । क्षमिता । क्षन्ता । अयं न षित् । भ्वादिस्तु षित् । अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा ॥ **क्लमु** क्लान्तौ । ष्ठिवुक्लमुचमामिति दीर्घः । क्लाम्यति । क्लमिता । अक्लमत् ॥ **मदी** हर्षे । माद्यति । अमदत् ॥ **असु** क्षेपणे । अस्यति । आस । असिता ॥ **अस्यतेस्थुक्** ।७।४।१७। अङि । अस्यतीत्यङ् । आस्थत् ॥ **यसु** प्रयत्ने ॥ **यसोऽनुपसर्गात्** [२] ।३।१।७१। **संयसश्च** ।३।१।७२। श्यन्वा । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ॥ **जसु** मोक्षणे । जस्यति ॥ **तसु** उपक्षये ॥ **दसु** च । तस्यति । अतसत् । दस्यति । अदसत् ॥ **वसु** स्तम्भे । वस्यति । नशसददेति निषेधः । ववास । ववसतुः । बशादिरिति मते तु । बेसतुः । बेसुः ॥ **व्युष** विभागे । व्युष्यति ॥ **विस** प्रेरणे । विसति । अविसत् ॥ **वुस** उत्सर्गे ।

---

१ अत्र श्लिषः इति आलिङ्गने इति च योगविभागः । तेन श्लिषश्श्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छलइगुपधादित्यस्याप्ययं नियमः । २ अत्र वदन्ति–यस इत्येवास्तु । ततः समो नियमार्थमिदम् । सोपसर्गाद्यसश्चेत्संपूर्वकादेवेति । एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणमुत्तरत्र च यसश्चेति ग्रहणं त्यक्तुं शक्यमिति ।

वुसति ॥ **मुस** खण्डने । मुस्यति ॥ **मसी** परिणामे । परिणामो विकारः ॥ **लुठ** विलोडने । लुठ्यति ॥ **उच** समवाये । उच्यति । उवोच । ऊचतुः । ऊचुः ॥ **भृशु भ्रंशु** अधःपतने । भृश्यति । बभर्श । अभृशत् । अनिदितामिति नलोपः । भ्रश्यति । बभ्रंश । अभ्रशत् ॥ **कृश** तनूकरणे । कृश्यति ॥ **ञितृष** पिपासायाम् । तृष्यति ॥ **हृष** तुष्टौ । श्यन्नङौ भौवादिकाद्विशेषः । हृष्यति । अहृषत् ॥ **रुष रिष** हिंसायाम् । तीषेति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ॥ **कुप** क्रोधे । कुप्यति । **गुप** व्याकुलत्वे ॥ **लुभ** गार्ध्ये । गार्ध्यमाकाङ्क्षा । लोभिता । लोब्धा । लोभिष्यति । भ्वादेरवृत्करणाल्लोभतीत्यप्याहुः ॥ **क्षुभ** संचलने । क्षुभ्यति ॥ **क्लिदू** आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम चिक्लिद्म ॥ **ञिमिदा** स्नेहने ॥ **मिदेर्गुणः** ।७।३।८२। इक इत्संज्ञकशकारादौ प्रत्यये । मेद्यति । अमिदत् ॥ **ञिक्ष्विदा** स्नेहनमोचनयोः । क्ष्विद्यति ॥ **ऋधु** वृद्धौ । ऋध्यति । आनर्ध ॥ **गृधु** अभिकाङ्क्षायाम् । गृध्यति । अगृधत् । **षूङ्** प्राणिप्रसवे । सूयते । सुषुवे । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता । **दूङ्** परितापे ॥ **दीङ्** क्षये ॥ **दीङो युडचि क्ङिति** ।६।४।६३। दीङः पर[1]स्याजादेः क्ङिति आर्धधातुकस्य युट् । ([2]वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ) । दिदीये ॥ **मीनातिमिनोतिदीङां ल्यपि च** ।६।४।५०। एषामात्वं ल्यपि चादशित्येज्निमित्ते । दाता । दास्यते । अदास्त ॥ **डीङ्** विहायसा गतौ । डीयते ॥ **पीङ्** पाने । पीयते ॥ **माङ्** माने । मायते । ममे । माता ॥ **जनी** प्रादुर्भावे ॥ **ज्ञाजनोर्जा** ।७।३।७८। शिति जायते । गमहनजनेति उपधाया लोपः । 'स्तोः श्चुना श्चुः' । जज्ञे । जनिता । जनिष्यते ॥ **दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्** ।३।१।६१। एभ्यश्च्लेश्चिण्वा एकवचने तशब्दे परे ॥ **चिणो लुक्** ।६।४।१०४। चिणः परस्य तशब्दस्य लुक् ॥ **जनिवध्योश्च** ।७।३।३५। न वृद्धि-

---

१ अजादेरिति । ङःसीत्यत्रेव उभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति सप्तम्याश्च षष्ठीकल्पनम् । २ आभीयत्वेनासिद्धत्वमाशङ्क्याह—वुग्युटाविति ।

श्रिणि ञ्णिंति कृति च । अजनि । अजनिष्ट ॥ **दीपी** दीप्तौ । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ॥**पद** गतौ । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥ **चिण्ते पदः** ।३।४।६०। अपादि । अपत्साताम् । अपत्सत ॥ **विद** सत्तायाम् । विद्यते । वेत्ता ॥ **बुध** अवगमने । बुध्यते । बोद्धा । एकाचो बशो भष्झषन्तस्येति भष्भावः । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् ॥ **युध** संप्रहारे । युध्यते । युयुधे । योद्धा । अयुद्ध ॥ **सृज** विसर्गे । सृज्यते । ससृजे । सृजिदृशोर्झल्यमकितीत्यमागमः । स्रष्टा । स्रक्ष्यते । सृक्षीष्ट । लिङ्सिचाविति कित्त्वम् । असृष्ट । असृक्षाताम् ॥ **मीङ्** हिंसायाम् । मीयते ॥ **रीङ्** श्रवणे । रीयते ॥ **लीङ्** श्लेषणे । लीयते ॥ **विभाषा लीयतेः** ।६।१।५१। लीयतेरिति यँका निर्देशो नतु श्यना । लीलीङोरात्वं स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्यते । एज्विषये किम् । लीयते । लिल्ये ॥ **व्रीङ्** वृणोत्यर्थे । व्रीयते । विव्रिये ॥ **मृष** तितिक्षायाम् । मृष्यति । मृष्यते । ममर्षिथ । ममृषे । ममृषिषे । मर्षितासि । मर्षितासे ॥ **णह** बन्धने । नह्यते । ननाह । 'नहो धः' इति धः । ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत् । अनद्ध ॥ **रञ्ज** रागे । रज्यति । रज्यते ॥ **शप** आक्रोशे । शप्यति । शप्यते । शकविभाषितोऽमर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति, शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । पुषादित्वादङ् । अशकत् । अशक्त । सेट्कोयमित्येके । तन्मते नानिट्केषु लृदित्पठितः । शकिता । शकिष्यति । शकिष्यते । इति दिवादिः ॥

अथ स्वादिगणः ॥ ५ ॥

षुञ् अँभिषवे ॥ **स्वादिभ्यः श्नुः** ।३।१।७३। कर्तरि सार्वधातुके । शपोऽपवादः । सुनोति । सुनुतः । हुश्नुवोरिति यण् । सुन्वन्ति । लोपश्चास्येति प्रत्ययेतो लोपः । सुन्वः । सुनुवः । सुनुते । सुन्वाते । सुन्वते । सुनुषे । सुषाव ।

---

१ घञि ञिति कृत्युदाहरणं जनः । णिति कृति तु जनकः । २ सार्वधातुके यगिणि विहितेन नतु श्यनेति । अन्यथा लीङ् इत्येव ब्रूयादिति भावः । ३ अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च । तत्र स्नानेऽकर्मकः ।

सुषुवे । सोता । सुनवानि[1] । सुनवै । सुनुयात् ॥ **स्तुसुधूञ्भ्यः परस्मैपदेषु** ।७।२।७२। सिच इट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् ॥ **सुनोतेः स्यसनोः** ।८।२।११७। सस्य षो न । विसोष्यति ॥ **षिञ्** बन्धने । विसिनोति ॥ **चिञ्** चयने[2] । चिनोति । चिनुते ॥ **विभाषा चेः** ।७।३।५८। अभ्यासाच्चेः कुत्वं वा सनि लिटि च । चिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट ॥ **स्तृञ्** आच्छादने । स्तृणोति । स्तृणुते । तस्तार । तस्तरे । गुणोर्तीति गुणः । स्तर्यात् ॥ **ऋतश्च संयोगादेः** ।७।२।४३। ऋदन्तात्संयोगादेर्लिङ्सिचोरिड्वा तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत ॥ **धूञ्** कम्पने । धुनोति धुनुते । दुधाव । दुधुवे । अधौषीत् । अधोष्यत् ॥ **धूञ्** कम्पने । धूनोति । धूनुते । स्वरतीति वेट् । दुधविथ । दुधोथ । किति लिटि तु ॥ **श्र्युकः किति** ।७।२।११। श्रिञ एकाच उगन्ताच्च गित्कितोरिण्न । इति प्राप्ते । क्रादिनियमान्नित्यमिट् । दुधुविव । दुधुविम । अधावीत् । अधविष्ट । अधोष्ट ॥ **कृञ्** हिंसायाम् । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत ॥ **वृञ्** वरणे । वृणोति । वृणुते ॥ **बभूथाततन्थजगृभ्मववर्थेति निगमे**[3] ।७।२।६४। एषां वेद इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृत । ववृवहे । वृतो वा । वरीता वरिता ॥ **लिङ्सिचोरात्मनेपदेषु** ।७।२।७३। वृङ्वृञ्भ्यामृदन्ताच्च परयोर्लिङ्सिचोरिड् वा तङि ॥ **न लिङि** ।७।२।३९। वृतो लिङ इटो न दीर्घः । वरिषीष्ट । वृषीष्ट । अवारीत् । अवरिष्ट । अवृत ॥ **टुदु** उपतापे । दुनोति ॥ **हि** गतौ वृद्धौ च ॥ **हिनुमीना** ।८।४।१५। उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः । प्रहिणोति ॥ **हेरचङि**[4] ।७।३।५६। अभ्यासात्सिनोतेर्हस्य कुत्वं नतु चङि ।

---

१ आडुत्तमस्येत्यादि कृते हुश्नुवोरिति यणं बाधित्वा परत्वाद्गुणः । २ चयनं रचनाविशेषः । ३ भूधातोस्तनोतेश्च थलि इडभावो निपात्यते वृणोतेस्थलि क्रादिसूत्रेणेण्निषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति नियमार्थं ववर्थग्रहणम् । ४ इह ण्यन्तस्य धात्वन्तरत्वात्केवलस्य त्वभ्यासनिमित्तप्रत्ययपरत्वाभावात्कुत्वप्राप्तिरेव नास्तीत्यचङीति निषेधो व्यर्थः सन् ज्ञापयति ण्यधिकस्यापि कुत्वं भवतीति । तेन जिघापयिषतीत्यादि सिद्धम् ।

जिघाय ॥ **आप्लृ** व्याप्तौ । आप्नोति । आप्नुतः । आप्नुवन्ति । आप्नुवः । आप्नुहि । ऌदित्त्वादङ् । आपत् ॥ **शक्लृ शक्तौ** । अशकत् ॥ **राध साध** संसिद्धौ । राध्नोति ॥ **राधो हिंसायाम्** ।६।४।१२३। एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । अपरेधुः । रेधिथ । राद्धा । साध्नोति । ससाध । साद्धा । असात्सीत् । असाद्धाम् ॥ **ञिधृषा** प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता ॥ **दम्भु** दम्भने[1] । अनिदितामिति नलोपः । दभ्नोति । ददम्भ । (श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वा) । कित्त्वपक्षे नलोपः । तस्याभीयत्वादसिद्धत्वेनैत्वाभ्यासलोपयोरप्राप्तौ । (दम्भेश्च एत्वाभ्यासलोपौ वक्तव्यौ) । देभतुः । ददम्भतुः । दम्भिता । दभ्यात् ॥ **तृप** प्रीणने ॥ **क्षुभ्नादिषु च** ।८।४।३९। न णत्वम् । तृप्नोति । ततर्प ॥ **अशू** व्याप्तौ संघाते च । अश्नुते ॥ **अश्नोतेश्च**[2] ।७।४।७२। दीर्घादभ्यासादवर्णात्परस्य नुट् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ॥ इति स्वादिः ॥

अथ तुदादिगणः ॥ ६ ॥

तुद व्यथने ॥ **तुदादिभ्यः शः** ।३।१।७७। शपोपवादः । तुदति[3] । तुदते । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ॥ **णुद** प्रेरणे । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता ॥ **भ्रस्ज** पाके । ग्रहिज्यावयीति संप्रसारणम् । सस्य श्चुत्वम् । तस्य जश्त्वम् । भृज्जते ॥ **भ्रस्जो रोपधयो रमन्यतरस्याम्** ।६।४।४७। भ्रस्जेरेफस्योपधायाश्च स्थाने रमागमो वार्धधातुके । मित्त्वादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभर्ष्ठ । बभ्रज्जतुः । बभ्रज्जिथ । स्कोरिति सलोपः । व्रश्चेति षः । बभ्रष्ठ । बभर्जे । बभ्रज्जे । भर्ष्टा । भ्रष्टा । भर्क्ष्यति । भ्रक्ष्यति । ङ्किति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन । भृज्ज्यात् । भृज्ज्यास्ताम् । भृज्ज्यासुः । भर्क्षीष्ट । भ्रक्षीष्ट । अभार्क्षीत् । अभ्राक्षीत् । अभर्ष्ट । अभ्रष्ट ।

---

१ लोकवञ्चनाय विहितकर्मानुष्ठानं दम्भः । २ अश्नोतेश्चेत्यत्र श्नुविकरणनिर्देशः क्र्यादेरशभोजन इत्यस्य माभूदित्येतदर्थम् । ३ परमपि लघूपधगुणं बाधित्वा नित्यत्वात् श इत्येके । अकृतव्यूहपरिभाषया गुणो न प्रवर्तत इत्यन्ये ।

कृष विलेखने । कृषति । कृषते । चकर्ष । चकृषे । क्रष्टा । कर्ष्टा । कृक्षीष्ट । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् । अकृष्ट । अकृक्षाताम् । अकृक्षत । स्पृशमृशेति सिज् वा । अकृक्षाताम् । अकृक्षन्त ॥ **मिल** संगमने । मिलति । मिलते । मिमेल । मेलिता । अमेलीत् ॥ **मुच्लृ** मोक्षणे ॥ **शे मुचादीनाम्** ।७।१।५९। मुच्लुप्विद्सिपृसिच्कृतखिद्पिशां नुम् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । लिङ्सिचाविति कित् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् ॥ **लुप्लृ** छेदने । लुम्पति । लुम्पते । लोप्ता । अलुपत् । अलुप्त ॥ **विद्लृ** लाभे । विन्दति विन्दते । विवेद । व्याघ्रभूतिमते सेट् । वेदिता । भाष्यमतेऽनिट् । परिवेत्ता ॥ **षिच** क्षरणे । सिञ्चति । सिञ्चते । असिचत्[1] । असिचत । असिक्त ॥ **लिप** उपदेहे । लिम्पति । लिम्पते । लेप्ता । लिपिसिचिह्वश्चेत्यङ् । अलिपत् । अलिप्त ॥ **कृती** छेदने । कृन्तति । चकर्त । कर्तिता । सेसिचीति वेट् । कर्तिष्यति । कर्त्स्यति । अकर्तीत् ॥ **खिद** परिदेवने । खिद्यति । चिखेद । खेत्ता ॥ **पिश** अवयवे । पिंशति । पेशिता ॥ **ओव्रश्च्** छेदने । वृश्चति । वव्रश्च । वव्रश्चिथ । वव्रष्ठ । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत्[3] । अव्राक्षीत्[4] ॥ **व्यच** व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् । व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते । अनसीति पर्युदासेन कृन्मात्रविषयत्वात् । **उछि** उञ्छे । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार ॥ **ऋच्छ** गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यॄतामिति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्च्छ[5] । आनर्च्छतुः । ऋच्छिता ॥ **उज्झ** उत्सर्गे । उज्झति । उज्झांचकार ॥ **लुभ** विमोहने । लुभति । तीषसहलुभेति

---

१ इह लिपिसिचिह्वश्चेति च्लेरङ् विधीयते सचाप्राप्तविधिः । इरित्त्वेतु विकल्पेन प्राप्तौ नित्यार्थो विधिरिति फलाभावः । २ वव्रश्चेत्यत्र लिट्यभ्यासस्येति संप्रसारणम् । उरदित्यत्वं रपरत्वं च । तस्याचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारणे इति निषेधाद्वस्य न संप्रसारणम् । ३ ऊदित्त्वात्पक्षे इट् । ४ स्कोरिति सलोपः व्रश्चेति षः षढोरिति कः ततः सस्य षत्वम् । ५ अनृच्छ इति पर्युदासान्नाम् ।

वेट् । लोभिता । लोब्धा । लोभिष्यति ॥ **तृप तृम्फ** तृप्तौ । तृपति । ततर्प । तर्पिता । अतर्पीत् । तृम्फति । (शे तृम्फादीनां नुम्वाच्यः) । आदिशब्दः प्रकारे[1] । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । ततृम्फ । तृफ्यात् ॥ **मृड** सुखने ॥ **पृड** च । मृडति । पृडति ॥ **शुन** गतौ । शुनति ॥ **इष** इच्छायाम् । इषुगमीति छः । इच्छति । तीषेति वेट् । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ॥ **कुट** कौटिल्ये । गाङ्कुटादीति ङित्त्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ॥ **पुट** संश्लेषणे । पुटति । पुटिता ॥ **स्फुट** विकसने । स्फुटति ॥ **स्फुर स्फुल** संचलने । स्फुरति । स्फुलति ॥ **स्फुरतिस्फुलत्योर्निर्निविभ्यः** ।८।३।७६। षत्वं वा । निस्फुरति । निष्फुरतीत्यादि ॥ **णू** स्तवने । परिणूतगुणोदयः[2] । नुवति । नुनाव । नुविता । इति कुटादयः ॥ **टुमस्जो** शुद्धौ । मज्जति । ममज्ज । मस्जिनशोरिति नुम् । (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः) संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति ॥ **रुजो** भङ्गे । अरौक्षीत् ॥ **भुजो** कौटिल्ये । रुजिवत् ॥ **विश** प्रवेशने । विशति ॥ **मृश** आमर्शने । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् । स्पृशमृशेति च्लेः सिच् ॥ **शद्लृ** विशरणगत्यवसादनेषु । विशरणं दुःखम् । सीदतीत्यादि[3] ॥ **शद्लृ** शातने ॥ **शदेः शितः** ।१।३।६०। शिद्भाविनोऽस्मात्तङानौ स्तः । शीयते । शीयताम् । अशीयत । शीयेत । शशाद । शत्ता । शत्स्यति । अशदत् । अशत्स्यत् ॥ **कॄ** विक्षेपे ॥ **ॠत इद्धातोः** ।७।१।१००। किरति । (ईत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन[4]) । चकार । चकरतुः । करिता । करीता । कीर्यात् । अकारीत् ॥ **किरतौ लवने** ।६।१।१४०। उपात्[5] किरतेः सुट् छेदेऽर्थे । उपस्किरति । (अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम्) । उपास्किरत् । उपचस्कार ॥ **हिंसायां प्रतेश्च**[6] ।६।१।१४१। उपा-

१ प्रकारो भेदसादृश्ये इत्यमरात्सादृश्य इत्यर्थः । २ श्युकः कितीतीण्निषेधः । ३ पाघ्राध्मास्थेति सीदादेशः । ४ परत्वाद्गुणवृद्धी भवत इति वक्तव्ये कुतोऽस्यारम्भ इत्यत्राहुः । परादप्यन्तरङ्गं बलवदितीत्वे प्राप्ते वार्तिकमिदमारब्धम् । ५ उपात्प्रतियत्ने इति सूत्रादुपादित्यनुवर्तते । लवने किं । उपकिरति । ६ चादुपात् । उरोविदारं प्रतिचस्करे नखैः इति माघः । कर्मणि लिट् ।

कृष विलेखने । कृषति । कृषते । चकर्ष । चकृषे । क्रष्टा । कर्ष्टा । कृक्षीष्ट । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् । अकृष्ट । अकृक्षाताम् । अकृक्षत । स्पृशमृशेति सिज् वा । अकृक्षाताम् । अकृक्षन्त ॥ **मिल** संगमने । मिलति । मिलते । मिमेल । मेलिता । अमेलीत् ॥ **मुच्लृ** मोक्षणे ॥ **शे मुचादीनाम्** ।७।१।५९। मुच्लुप्विद्सिप्सिच्कृतखिद्पिशां नुम् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । लिङ्सिचाविति कित् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् ॥ **लुप्लृ** छेदने । लुम्पति । लुम्पते । लोप्ता । अलुपत् । अलुप्त ॥ **विद्लृ** लाभे । विन्दति विन्दते । विवेद । व्याघ्रभूतिमते सेट् । वेदिता । भाष्यमतेऽनिट् । परिवेत्ता ॥ **षिच** क्षरणे । सिञ्चति । सिञ्चते । [1]असिचत् । असिचत । असिक्त ॥ **लिप** उपदेहे । लिम्पति । लिम्पते । लेप्ता । लिपिसिचिह्वश्चेत्यङ् । अलिपत् । अलिप्त ॥ **कृती** छेदने । कृन्तति । चकर्त । कर्तिता । सेसिचीति वेट् । कर्तिष्यति । कर्त्स्यति । अकर्तीत् ॥ **खिद** परिदेवने । खिद्यति । चिखेद । खेत्ता ॥ **पिश** अवयवे । पिंशति । पेशिता ॥ **ओव्रश्चू** छेदने । वृश्चति । वव्रश्च । वव्रश्चिथ । वव्रष्ठ । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अ[3]व्रश्चीत् । [4]अव्राक्षीत् ॥ **व्यच** व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् । व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते । अनसीति पर्युदासेन कृन्मात्रविषयत्वात् । **उछि** उञ्छे । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार ॥ **ऋच्छ** गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यृतामिति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । [5]आनर्च्छ । आनर्च्छतुः । ऋच्छिता ॥ **उज्झ** उत्सर्गे । उज्झति । उज्झांचकार ॥ **लुभ** विमोहने । लुभति । तीषसहलुभेति

---

१ इह लिपिसिचिह्वश्चेति च्लेरङ् विधीयते सचाप्राप्तविधिः । इरित्त्वेतु विकल्पेन प्राप्तौ नित्यार्थो विधिरिति फलाभावः । २ वव्रश्चेत्यत्र लिट्यभ्यासस्येति संप्रसारणम् । उरदित्यत्वं रपरत्वं च । तस्याचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारणे इति निषेधाद्वस्य न संप्रसारणम् । ३ ऊदित्त्वात्पक्षे इट् । ४ स्कोरिति सलोपः व्रश्चेति षः षढोरिति कः ततः सस्य षत्वम् । ५ अनृच्छ इति पर्युदासान्नाम् ।

वेट् । लोभिता । लोब्धा । लोभिष्यति ॥ **तृप तृम्फ** तृप्तौ । तृपति । ततर्प । तर्पिता । अतर्पीत् । तृम्फति । (शे तृम्फादीनां नुम्वाच्यः) । आदिशब्दः [1]प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । ततृम्फ । तृफ्यात् ॥ **मृड** सुखने ॥ **पृड** च । मृडति । पृडति ॥ **शुन** गतौ । शुनति ॥ **इष** इच्छायाम् । इषुगमीति छः । इच्छति । तीषेति वेट् । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ॥ **कुट** कौटिल्ये । गाङ्कुटादीति ङित्त्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ॥ **पुट** संश्लेषणे । पुटति । पुटिता ॥ **स्फुट** विकसने । स्फुटति ॥ **स्फुर स्फुल** संचलने । स्फुरति । स्फुलति ॥ **स्फुरतिस्फुलत्योर्निर्निविभ्यः** ।८।३।७६। षत्वं वा । निस्फुरति । निष्फुरतीत्यादि ॥ **णू** स्तवने । [2]परिणूतगुणोदयः । नुवति । नुनाव । नुविता । इति कुटादयः ॥ **टुमस्जो** शुद्धौ । मज्जति । ममज्ज । मस्जिनशोरिति नुम् । (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः) संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति ॥ **रुजो** भङ्गे । अरौक्षीत् ॥ **भुजो** कौटिल्ये । रुजिवत् ॥ **विश** प्रवेशने । विशति ॥ **मृश** आमर्शने । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् । स्पृशमृशेति च्लेः सिच् ॥ **शदॢ** विशरणगत्यवसादनेषु । विशरणं दुःखम् । [3]सीदतीत्यादि ॥ **शदॢ** शातने ॥ **शदेः शितः** ।१।३।६०। शिद्भाविनोऽस्मात्तङानौ स्तः । शीयते । शीयताम् । अशीयत । शीयेत । शशाद । शत्ता । शत्स्यति । अशदत् । अशत्स्यत् ॥ **कॄ** विक्षेपे ॥ **ॠत इद्धातोः** ।७।१।१००। किरति । ([4]ईत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन) । चकार । चकरतुः । करिता । करीता । कीर्यात् । अकारीत् ॥ **किरतौ लवने** ।६।१।१४०। [5]उपात्किरतेः सुट् छेदेऽर्थे । उपस्किरति । (अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम्) । उपास्किरत् । उपचस्कार ॥ **[6]हिंसायां प्रतेश्च** ।६।१।१४१। उप्रा-

---

१ प्रकारो भेदसादृश्ये इत्यमरात्सादृश्य इत्यर्थः । २ श्युकः कितीतीण्निषेधः । ३ पाघ्राध्मास्थेति सीदादेशः । ४ परत्वाद्गुणवृद्धी भवत इति वक्तव्ये कुतोऽस्यारम्भ इत्यत्राहुः । परादप्यन्तरङ्गं बलवदितीत्वे प्राप्ते वार्तिकमिदमारब्धम् । ५ उपात्प्रतियत्ने इति सूत्रादुपादित्यनुवर्तते । लवने किं । उपकिरति । ६ चादुपात् । उरोविदारं प्रतिचस्करे नखैः इति माघः । कर्मणि लिट् ।

त्प्रतेश्च किरतेः । सुट् हिंसायाम् । उपस्किरति । प्रतिस्किरति ॥ **गॄ** निगरणे ॥ **अचि विभाषा** ।८।२।२१। गिरते रेफस्य लोऽजादौ प्रत्यये । गिरति । गिलति । गरिता । गरीता । गलिता । गलीता ॥ **प्रच्छ** ज्ञीप्सायाम् । ग्रहिज्येति संप्रसारणम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छुः । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् ॥ **मृङ्** प्राणत्यागे ॥ **म्रियतेर्लुङ्लिङोश्च** ।१।३।६१। लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङानौ नान्यत्र । ङित्त्वं स्वरार्थम् । रिङ् । इयङ् । म्रियते । ममार । ममर्थ । मम्रिव । मम्रिम । मर्ता । मरिष्यति । मृषीष्ट । अमृत ॥ **पृङ्** व्यायामे । प्रायेणायं व्याङ्पूर्वः । व्याप्रियते । व्यापप्रे । व्यापरिष्यते । ह्रस्वादङ्गादिति सिज्लोपः । व्यापृत । व्यापृषाताम् ॥ **जुषी** प्रीतिसेवनयोः । जुषते । जुजुषे ॥ **ओविजी** भयसंचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते ॥ **विज इट्** ।१।१।२। विजेः पर इडादिप्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते । **ओलजी ओलस्जी** व्रीडने । लजते । लेजे । लज्जते । ललज्जे ॥ इति तुदादिः ॥

अथ रुधादिगणः ॥ ७ ॥

रुधिर् आवरणे ॥ **रुधादिभ्यः श्नम्** ।३।१।७८। शपोऽपवादः । रुणद्धि । 'श्नसोरल्लोपः' । रुन्द्धः । रुन्धन्ति । रुणत्सि । रुन्द्धः । रुन्द्ध । रुणध्मि । रुन्ध्वः । रुन्ध्मः । रुन्धे । रुन्धाते । रुन्त्से । रुन्धाथे । रुन्द्धे । रुन्धे । रुन्ध्वहे । रुन्ध्महे । रुरोध । रुरुधे । रोद्धा । रोत्स्यति । रोत्स्यते । रुणद्धु । रुन्द्धात् । रुन्द्धाम् । रुन्धन्तु । रुन्धि । रुणधानि । रुणधाव । रुणधाम । रुन्द्धाम् । रुन्धाताम् । रुन्धताम् । रुन्त्स्व । रुणधै । रुणधावहै । रुणधामहै । अरुणत् २ । अरुन्द्धाम् । अरुन्धन् । दश्चेति रुः । अरुणः[1] । अरुणत् २ । अरुन्द्धम् । अरुन्द्ध । अरुन्द्ध । अरुन्धाताम् । अरुन्धत । रुन्ध्यात् । रुन्धीत । रुध्यात् । रुत्सीष्ट । अरुधत् । अरौत्सीत् । अरोत्स्यत् । अरोत्स्यत ॥ **भिदिर्** विदारणे ॥ **छिदिर्** द्वैधीकरणे ॥ **युजिर्** योगे ॥ **रिचिर्** विरेचने । रिणक्ति । रिङ्क्ते । रिरेच । रेक्ता । अरि-

१ सिपि दश्चेति रुर्वा । एवमभिन इत्यत्रापि ।

णक् । अरिचत् । अरैक्षीत् । अरिक्त ॥ **विचिर्** पृथग्भावे । विनक्ति । विङ्क्ते ॥ **क्षुदिर्** संपेषणे । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त ॥ **उच्छृदिर्** दीप्तिदेवनयोः । छृणत्ति । छृन्ते । चच्छर्द । सेसिचीति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छर्त्स्यति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट ॥ **उतृदिर्** हिंसानादरयोः । तृणत्ति । तृन्ते ॥ **कृती** वेष्टने । कृणत्ति ॥ **तृह हिसि** हिंसायाम् ॥ **तृणह इम्** ।७।३।९२। तृहः श्नमि कृते इम् हलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् ॥ **श्नान्नलोपः** ।६।४।२३। हिनस्ति । जिहिंस । हिंसिता ॥ **उन्दी क्लेदने** । उनत्ति । उन्तः । उन्दन्ति । उन्दांचकार । औनत् । औन्तात् । औन्दन् । औनः । औनदम् ॥ **अञ्जू** व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अञ्जिता । अङ्क्ता । अङ्ग्धि । अनजानि । आनक् ॥ **अञ्जेः सिचि** ।७।२।७१। अञ्जेः सिचो नित्यमिट्[3] । आञ्जीत् ॥ **तञ्चू** संकोचने । तनक्ति । तङ्क्ता । तञ्चिता ॥ **ओविजी** भयसंचलनयोः । विनक्ति । विङ्क्तः । विज इडिति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ॥ **शिष्लृ** विशेषणे । शिनष्टि । शिंष्टः । शिंषन्ति । शिनक्षि । शिशेष । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । शिण्ढि । शिनषाणि । शिंष्यात् । शिष्यात् । अशिषत् । अशेक्ष्यत् ॥ एवं **पिष्लृ** संचूर्णने ॥ **भञ्जो** आमर्दने । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता ॥ **भुज** पालनाऽभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ॥ **भुजोऽनवने**[4] ।१।३।६६। तङानौ स्तः । ओदनं भुङ्क्ते । अनवने किम् । महीं भुनक्ति ॥ **ञिइन्धी** दीप्तौ । इन्धे । इन्धाते । इन्धते । इन्त्से । इन्धांचक्रे । इन्धिता । इन्धाम् । इन्धाताम् । इन्धताम् । इन्धै । ऐन्ध । ऐन्धाताम् । ऐन्धत । ऐन्धाः ॥ **विद** विचारणे । विन्ते । वेत्ता ॥ इति रुधादिः ॥

---

१ उकारः क्त्वायामिड्विकल्पार्थः । २ श्नमः परस्य नस्य लोपः स्यात् । ३ विभाषाग्रहणं नानुवर्तत इति भावः । ४ अनवने अवनं पालनं तद्भिन्ने ।

अथ तनादिगणः ॥ ८ ॥

तनु विस्तारे ॥ **तनादिकृञ्भ्य उः** ।३।१।७९। तनोति । तनुते । ततान । तेने । तनिता । तनिष्यति । तनिष्यते । तनोतु । तनुताम् । अतनोत् । अतनुत । तनुयात् । तन्वीत । तन्यात् । तनिषीष्ट । अतनीत् । अतानीत् ॥ **तनादिभ्यस्तथासोः** ।२।४।७९। तनादेः सिचो वा लुक् तथासोः[1] । अनुदात्तोपदेशेति नलोपः । अतत । अतनिष्ट[2] । अतथाः । अतनिष्ठाः । अतनिष्यत् । अतनिष्यत ॥ **षणु** दाने । सनोति । सनुते । ये विभाषेति आत्वम् । सायात् । सन्यात् ॥ **जनसनखनां सञ्झलोः** ।६।४।४२। एषामाकारो झलादौ सनि झलादौ क्ङिति । असात । असनिष्ट । असाथाः । असनिष्ठाः ॥ **क्षणु** हिंसायाम् । क्षणोति । क्षणुते । ह्म्यन्तेति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ॥ **क्षिणु** च । उप्रत्यये लघूपधगुणो वा । क्षिणोति । क्षेणोति । क्षेणिता । अक्षेणीत् । अक्षित । अक्षेणिष्ट ॥ **तृणु** अदने । तृणोति । तर्णोति । तृणुते । तर्णुते ॥ **डुकृञ्** करणे । करोति । 'अत उत्सार्वधातुके' । कुरुतः । हलिचेति दीर्घे प्राप्ते ॥ **न भकुर्छुराम्** ।८।२।७९। भस्य कुर्छुरोरुपधाया न दीर्घः । कुर्वन्ति ॥ **नित्यं करोतेः** ।६।४।१०८। करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः । कुर्वः । कुर्मः । कुरुते । चकार । चकर्थ । चकृव । चक्रे । कर्ता । करिष्यति । करिष्यते । करोतु । कुरुताम् । अकरोत् । अकुरुत ॥ **ये च** ।६।४।१०९। कृञ उलोपो यादौ प्रत्यये । कुर्यात् । कुर्वीत । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत । अकरिष्यत् । अकरिष्यत ॥ **संपरिभ्यां करोतौ भूषणे** ।६।१।१३७। **समवाये च** ।६।१।१३८। आभ्यां परस्य करोतेः सुट् भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । संघीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः इति ज्ञापकात् ॥ **उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च** ।६।१।१३९। कृञः सुट् । चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षि-

---

१ थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न यूयमतनिष्ट । २ लुगभावपक्षे इट् ।

कदेशपूरणम् । [1]उपस्कृता कन्या । [2]उपस्कृता ब्राह्मणाः । एधोदकस्योपस्कुरुते[3] । उपस्कृतं भुङ्क्ते[4] । उपस्कृतं ब्रूते[5] ॥ **वनु** याचने । वनुते । ववने ॥ **मनु** अवबोधने । मनुते । मेने । मनिता । अमनुत । मन्वीत । मनिषीष्ट ॥ इति तनादिः ॥

अथ क्र्यादिगणः ॥ ९ ॥

डुक्रीञ् द्रव्यविनिमये ॥ **क्र्यादिभ्यः श्ना** ।३।१।८१। शपोऽपवादः । क्रीणाति । 'ई हल्यघोः' । क्रीणीतः । 'श्नाभ्यस्तयोरातः' । क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीणीवः । क्रीणीमः । क्रीणीते । क्रीणाते । क्रीणते । क्रीणीषे । क्रीणाथे । क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्रयिथ । चिक्रेथ । चिक्रिये । क्रेता । क्रेष्यति । क्रेष्यते । क्रीणातु । क्रीणीतात् । क्रीणीताम् । क्रीणाताम् । क्रीणताम् । क्रीणीयात् । क्रीणीत । क्रीयात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट । अक्रेष्यत् । अक्रेष्यत ॥ **प्रीञ्** तर्पणे कान्तौ च । प्रीणाति । प्रीणीते ॥ **श्रीञ्** पाके । श्रीणाति । श्रीणीते ॥ **मीञ्** हिंसायाम् । प्रमीणाति । 'हिनुमीना' इति णत्वम् । प्रमीणीते । मीनातीत्यात्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । **षिञ्** बन्धने । सिनाति । सिनीते । सिषाय । सिष्ये । सेता ॥ **स्कुञ्** आप्रवणे ॥ **स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च** ।३।१।८२। चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्कुवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तन्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्थाः परस्मैपदिनः ॥ **हलः श्नः शानज्झौ** ।३।१।८३। स्तभान[6] ॥ **जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च** ।३।१।५८। च्लेरङ् वा । व्यष्टभत् । अस्तम्भीत् ॥ **युञ्** बन्धने । युनाति । युनीते । योता ॥ **क्नूञ्** शब्दे । क्नूनाति । क्नूनीते । क्नविता ॥ **द्रूञ्** हिंसायाम् । द्रूणाति । द्रूणीते ॥ **पूञ्** पवने ॥ **प्वादीनां**

---

१ अलंकृतेत्यर्थः । २ समुदिता इत्यर्थः । ३ गुणाधानं करोतीत्यर्थः । ४ विकृतमित्यर्थः । ५ वाक्याध्याहारेण ब्रूते इत्यर्थः । ६ अतो हेरित्यारम्भसामर्थ्यात्संनिपातपरिभाषाया अप्रवृत्तेर्हेर्लुक् ।

ह्रस्वः ।७।३।८०। पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली क्ली प्ली एषां चतुर्विंशतेर्ह्रस्वः शिति । पुनाति । पुनीते । पविता ॥ **लूञ्** छेदने । लुनाति । लुनीते ॥ **स्तॄञ्** आच्छादने । स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । तस्तरे । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । 'ॠत इद्धातोः' । स्तीर्यात् । स्तरिषीष्ट । स्तीर्षीष्ट । 'सिचि च परस्मैपदेषु' । अस्तारीत् । अस्तारिष्टाम् । अस्तारिषुः । अस्तरिष्ट । अस्तीर्ष्ट ॥ **कॄञ्** हिंसायाम् । कृणाति । कृणीते । चकार । चकरे । **वॄञ्** वरणे । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । एदोष्ठ्येत्युत्वम् । वूर्यात्[1] । वरिषीष्ट । वूर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट । अवूर्ष्ट ॥ **धूञ्** कम्पने । धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । 'स्तुसुधूञ्भ्यः परस्मैपदेषु' । अधावीत् । अधविष्ट ॥ **ग्रह** उपादाने । गृह्णाति । गृह्णीते । जग्राह । जगृहे ॥ **ग्रहोऽलिटि दीर्घः ।७।२।३७।** एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । गृहाण । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीषाताम् । **कुष** निष्कर्षे । कुष्णाति । कोषिता ॥ **निरः कुषः ।७।२।४६।** वलादेरार्धधातुकस्येड्वा । निष्कोषिता । निष्कोष्टा । निरकोषीत् । शल इगुपधादिति क्सः । निरकुक्षत् ॥ **अश** भोजने । अश्नाति । आश । अशिता । अश्नातु । अशान ॥ **ज्ञा** अवबोधने । ज्ञाजनोरिति जादेशः । जानाति । जज्ञौ ॥ **पॄ** पालनपूरणयोः । पृणाति ॥ **शॄ** हिंसायाम् । शृणाति । शॄदॄप्रां ह्रस्वो वेति पक्षे यण् । शश्रतुः । शशरतुः । **दॄ** विदारणे । दृणाति । दद्रतुः । ददरतुः ॥ **जॄ** वयोहानौ । जृणाति ॥ **मुष** स्तेये । मुष्णाति । मोषिता ॥ **पुष** पुष्टौ । पुष्णाति । पोषिता ॥ **बन्ध** बन्धने । बध्नाति । बबन्ध । बबन्धिथ । बन्धा । भन्त्स्यति । अभान्त्सीत् । अबान्धाम् । अभान्त्सुः ॥ **क्लिश्** विबाधने । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् ॥ **वृङ्** संभक्तौ । वृणीते । वव्रे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत ॥ इति क्र्यादिः ॥

---

१ दन्तोष्ठ्योऽपि ओष्ठ्यग्रहणेन गृह्यत इत्याह—वूर्यादिति ।

अथ चुरादिगणः ॥ १० ॥

चुर स्तेये ॥ **सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्**[1] ।३।१।२५। स्वार्थे ।पुगन्तेति गुणः । सनाद्यन्ता इति धातुत्वम् तिप्शबादि । गुणायादेशौ । चोरयति ॥ **णिचश्च** ।१।३।७४। णिजन्तादात्मनेपदं कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रीति चङ् । णौ चङीति ह्रस्वः । चङीति द्वित्वम् । हलादिः शेषः । दीर्घो लघोरित्यभ्यासस्य दीर्घः । अचूचुरत् ॥ **चिति** स्मृत्याम् । चिन्तयति । अचिचिन्तत् । चिन्तेति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यादित्यादौ नलोपो न । चिन्तति । चिन्तेदित्यादि ॥ **यत्रि** संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम्[2] । एवं **कुद्रि** अनृतभाषणे ॥ **तत्रि** कुटुम्बधारणे ॥ **मत्रि** गुप्तपरिभाषणे । तन्त्रयते । मन्त्रयते । एतौ आत्मनेपदिनौ ॥ **स्फुडि** परिहासे । स्फुण्डयति ॥ **पीड** अवगाहे ॥ **भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्** ।७।४।३। एषामुपधाया ह्रस्वो वा चङ्परे णौ । अपीपिडत् । अपिपीडत् ॥ **प्रथ** प्रख्याने । प्रथयति ॥ **अत्स्मृदृत्वरप्रथम्रदस्तॄस्पशाम्** ।७।४।९५। एषामभ्यासस्याकारश्चङ्परे णौ । इत्वापवादः । अपप्रथत् ॥ **पृथ** प्रक्षेपे । पर्थयति ॥ **उर्ऋत्**[3] ।७।४।७। उपधाया ऋवर्णस्य ऋद्वा चङ्परे णौ ईर्रारामपवादः[4] । अपीपृथत् । अपपर्थत् ॥ **लुण्ठ** स्तेये । लुण्ठयति ।

---

१ चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थ इति । करणे इत्यस्य तु नानुवृत्तिः विच्छिन्नत्वादिति भावः । २ यत्रितत्रिमत्र्यादिषु इकारो व्यर्थ एव नतु ज्ञापनार्थः । तेषां संयोगान्तत्वात् यन्त्रतन्त्रमन्त्र इति नकारे पठितेऽपि अनिदितामिति लोपो न लभ्यते । नकारस्यानुपधात्वात् चिन्त्यादित्यत्र तु चिन्त स्मृत्यामिति नकारोपधपाठे नलोपः स्यादेवेति तद्वारणाय कृत इकारस्तु ज्ञापक इति भावः । ३ जिघ्रतेर्वेत्यतो वेति वर्तते । ४ ऋकारोपधे उपधायाश्चेत्यचीकृतदित्यादौ इर् प्राप्तः, अमीमृजदित्यत्र मृजेर्वृद्धिरित्यार् प्राप्तः, इतरेषां ऋदुपधानां गुणेनापीपृथदित्यादावर् प्राप्त इति विवेकः ।

अलुलुण्ठत् ॥ **तड** आघाते । ताडयति । अतीतडत् ॥ **मडि** भूषायां हर्षे च । मण्डयति । अममण्डत् ॥ **भडि** कल्याणे । भण्डयति । अबभण्डत् ॥ **छर्द** वमने । छर्दयति । अचछर्दत् ॥ **चुद** संचोदने । चोदयति । अचूचुदत् ॥ **पाल** रक्षणे । पालयति । अपीपलत् ॥ **पूज** पूजायाम् । पूजयति । अपूपुजत् ॥ **कॄत** संशब्दने । **उपधायाश्च** ।७।१।१०१। धातोर्ॠत इत् । रपरत्वम् । उपधायां चेति दीर्घः । कीर्तयति । अचीकृतत् । अचिकीर्तत् ॥ **म्लेच्छ** अव्यक्तायां वाचि । म्लेच्छयति । अमिम्लेच्छत् ॥ **ईड** स्तुतौ । ईडयति ॥ **पिडि** संघाते । पिण्डयति ॥ **रुष** रोषे । रोषयति । अरूरुषत् ॥ **तुल** उन्माने । तोलयति । अतूतुलत् ॥ **शुल्ब** माने । शुल्बयति । अशुशुल्बत् ॥ **घुषिर्** विशब्दने । घोषयति । अजूघुषत् ॥ **पट पुट लुट तुजि मिजि पिजि लुजि भजि लघि त्रसि पिसि कुसि दसि कुशि घट घटि बृहि बर्ह बल्ह गुप धूप विच्छ चीव पुथ लोकृ चोचृ णद कुप तर्क वृतु वृधु** भाषार्थाः । पाटयति । पोटयति । लोटयति । तुञ्जयति । एवं परेषाम् । घाटयति । घण्टयति । **नाग्लोपिशास्वृदिताम्** ।७।४।२। णिच्यग्लोपिनः शास्तेर्ॠदितां चोपधाया ह्रस्वो न चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति वर्धयति । 'आधृषाद्वा' । इत ऊर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ॥ **युज पृच** संयमने । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ॥ **अर्च** पूजायाम् ॥ **षह** मर्षणे । साहयति । 'स एवायं नागः सहति कलभेभ्यः परिभवम्' ॥ **वृञ्** वरणे । वारयति । वरति । वरते ॥ **जॄ** वयोहानौ । जारयति । जरति ॥ **शिष** असर्वोपयोगे । शेषयति । शेषति । शेष्टा । अशिक्षत् ॥ **तप** दाहे । तापयति । तपति । तप्ता ॥ **तृप** तृप्तौ । तर्पयति । तर्पति ॥ **हिसि** हिंसायाम् । हिंसयति । हिंसति ॥ **अर्ह** पूजायाम् । **छद** अपवारणे । छादयति । छदति । छदते ॥ **धूञ्**[1] कम्पने । (धून्प्रीञोर्नुक्[2])

---

१ अयं स्वादौ क्र्यादौ तुदादौ चुरादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये—'धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् । वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च । २ केचित्तु धून्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धूनोतेरेव नुकमाहुः । धवयति ।

णौ । धनूयति । धवति । धवते ॥ **प्रीञ्** तर्पणे । प्रीणयति । प्रीणयते । प्रीयति । प्रीयते ॥ **वच** परिभाषणे । वाचयति । वचति वक्ता । अवाक्षीत् ॥ **मान** पूजायाम् । मानयति । मानति । मानिता ॥ **भू** प्राप्तौ आत्मनेपदी । भावयते । भवते । णिच्संनियोगेनैवात्मनेपदमित्येके । भवति ॥ **मार्ग** अन्वेषणे ॥ **धृष** प्रहसने । धर्षयति । धर्षति । अथादन्ताः ॥ **कथ** वाक्यप्रबन्धे । अल्लोपः ॥ **अचः परस्मिन्पूर्वविधौ ।१।५।५७।** परनिमित्तोऽजादेशः स्थानिवत्स्यात् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति स्थानिवत्त्वान्नोपधाया वृद्धिः । कथयति । अग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचकथत् ॥ **गण** संख्याने । गणयति ॥ **ई च गणः ।७।४।९४।** गणेरभ्यासस्य ईत्स्यात् चादच्चङ्परे णौ । अजीगणत् । अजगणत् ॥ **रच** प्रतियत्ने । रचयति । अररचत् ॥ **कल** गतौ संख्याने च । कलयति । अचकलत् । **मह** पूजायाम् । महयति ॥ **सूच** पैशून्ये । सूचयति । अषोपदेशत्वान्न षः । असुसूचत् ॥ **कुमार** क्रीडायाम् । कुमारयति । अचुकुमारत् ॥ **ऊन** परिहाणे । ऊनयति । ओः पुयण्जीति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहो लिङ्गम् । णिच्येच[2] आदेशो न द्वित्वे कर्तव्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठितरूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदित्यादि सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वम् । तत उत्तरखण्डे अल्लोपः । औननत् ॥ **ध्वन** शब्दने । ध्वनयति । अदध्वनत् ॥ **सूत्र** वेष्टने । सूत्रयति ॥ **मूत्र** प्रस्रवणे । मूत्रयति । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । मूत्रति । आगर्वादात्मनेपदिनः ॥ **पद** गतौ । पदयते । अपपदत ॥ **गृह** ग्रहणे ॥ **मृग** अन्वेषणे । मृगयते ॥ **शूर वीर** विक्रान्तौ । शूरयते । वीरयते ॥ **गर्व** माने । गर्वयते ॥ इति चुरादयः ॥

---

१ अत्स्मृदृत्वर इत्यत्र योऽत्स चकारेण समुच्चीयते । २ प्रतिषेधो मुख्य इत्यभिप्रेत्येदमुक्तम् । प्रतिषेधः स्थानिवद्भावस्याप्युपलक्षणमिति बोध्यम् ।

अथ णिच्प्रक्रिया ॥ १ ॥

स्वतन्त्रः कर्ता[1] ।१।४।५४। क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ **तत्प्रयोजको हेतुश्च**[2] ।१।४।५५। कर्तृप्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च ॥ **हेतुमति च**[3] ।३।१।२६। प्रयोजकव्यापारे प्रेरणादौ वाच्ये धातोर्णिच् ॥ भवन्तं प्रेरयति भावयति ॥ **ओः पुयण्ज्यपरे**[4] ।७।४।८०। सनि परे यदङ्गं तदवयवो योऽभ्यासस्तस्योत इत्स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् ॥ **मूङ्** बन्धने । अमीमवत् । अयीयवत् ॥ **रु** शब्दे । अरीरवत् । अलीलवत् । अजीजवत् । पुयण्जीति किम् । नुनावयिषति । अपरे किम् । बुभूषति ॥ **स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा** ।७।४।८१। एषामभ्यासोकारस्येत्वं वा सनि अवर्णपरे धात्वक्षरे परे । असिस्रवत् । इत्यादि । अवर्णपरे किम् । अशूशुषत् । णिजन्ताण्णिच् । परत्वाद्वृद्धौ प्राप्तायाम् । ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति णिलोपः । चोरयति । णौ चङीति ह्रस्वः । दीर्घो लघोरिति दीर्घः । न चाग्लोपित्वाद्द्वयोरप्यसंभवः । ण्याकृतिनिर्देशात् । अचूचुरत् ॥ **टुओश्वि** गतिवृद्ध्योः ॥ **णौ च संश्चङोः** ।३।१।३१। सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । (संप्रसारणं तदाश्रयं च कार्यं बलवत्) इति वचनात्संप्रसारणम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥ **स्तम्भुसिवुसहां चङि** ।८।३।११६। उपसर्गादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् ॥ **स्वापेश्चङि** ।७।३।११८। ण्यन्तस्य स्वापेश्चङि संप्रसारणम् । असूषुपत् ॥ **हनस्तोऽचिण्णलोः** ।७।३।३२। चिण्णल्वर्जे ञिति णिति । घातयति ॥ **अर्ति**-

---

१ प्रधानीभूतधात्वर्थाश्रयः । २ तच्छब्देन स्वतन्त्रः कर्तेति पूर्वसूत्रोपात्तः कर्ता परामृश्यते तस्य कर्तुः प्रयोजकः प्रेरकः । तद्व्यापारानुकूलव्यापारवानित्यर्थः । चकारः संज्ञाधिकारबाधनार्थस्तदाह—हेतुसंज्ञः कर्तृसंज्ञश्चेति । ३ स्वनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमान्व्यापारः । तस्मिन्वाच्ये णिच् । ४ पुयण्जीति समाहारद्वन्द्वात्सप्तम्येकवचनम् । अपर इति बहुव्रीहिः ।

ह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ ।७।३।३६। स्थापयति ॥ **तिष्ठतेरित्** ।७।४।५। उपधायाश्चङ्परे णौ । अतिष्ठिपत् ॥ **जिघ्रतेर्वा** ।७।४।६। उपधाया इत्वं चङ्परे णौ । अजिघ्रपत् । अजिघ्रिपत् ॥ **शाच्छासाह्वाव्यावेपां युक्** ।७।३।३७। णौ। शाययति । अशीशयत् । ह्वाययति ॥ **ह्वः संप्रसारणम्** ।६।१।३२। सन्परे चङ्परे च णौ । (काण्यादीनां वा) । चङ्परे णौ उपधाया ह्रस्वो वा । ण्यन्ताः कणरणभणश्रणलुपहेठाः षट् भाष्ये । ह्वायिवाणिलोटिलोचयश्चत्वारोऽधिका न्यासे । चाणिलोठी अप्यन्यत्र । इत्थं काण्यादयो द्वादश । अजूहवत् । अजुहावत् । पाययति ॥ **लोपः पिबतेरीच्चाभ्यासस्य** ।७।४।४। पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत्[1] । (पातेर्णौ लुग्वक्तव्यः) । पुकोऽपवादः ॥ **पाल रक्षणे । वो विधूनने जुक्** ।७।३।३८। णौ । वाजयति । विधूनने किम् । केशान्वापयति ॥ **शदेरगतौ तः** ।७।३।४२। णौ । शातयति । गतौ तु । गाः शादयति गोविदः । गमयतीत्यर्थः ॥ **रुहः पोऽन्यतरस्याम्** ।७।३।४३। णौ । रोपयति । रोहयति ॥ **दोषो णौ** ।६।४।९०। दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥ **वा चित्तविरागे** ।६।४।९१। विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ **उभौ साभ्यासस्य** ।८।४।२१। साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत्[2] ॥ **णौ गमिरबोधने** ।२।४।४६। इणः । गमयति । बोधने तु । प्रत्याययति ॥ **घट चेष्टायाम्** ॥ **घटादयो मितः** ॥ **जनीजॄष्क्नसुरञ्जोऽमन्ताश्च** । मितः । **'ज्वलह्वलह्मलनमामनुपसर्गाद्वा'** । एषा मित्त्वं वा ॥ **'ग्लास्नावनुवमां च'**। 'अनुपसर्गादेषां मित्त्वं वा । **'न कम्यमिचमाम्'** । अमन्तत्वात्प्राप्तं मित्त्वमेषां न ॥ **'यमोऽपरिवेषणे'** । मित्त्वं न । **'स्खदिरवपरिभ्यां च'**। मित्र ॥ **मितां ह्रस्वः**

---

१ उपधालोपस्य द्वित्वे कर्तव्ये प्रतिषेधात् कृते लोपे स्थानिवद्भावाद्वा पाय्शब्दस्य द्वित्वे हलादिःशेषे ईकारः । स च अनभ्यासविकार इति निषेधादन्त्यस्यादेशः । २ इह पूर्वं णत्वं कृत्वा पश्चात् द्वित्वे कृते प्राणिणदित्यादिरूपसिद्धावयमारम्भः 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यत्वज्ञापनार्थः । तेन ऊर्णुनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाभावः सिद्धः ॥

।६।४।९२। घटादीनां च णावुपधाया ह्रस्वः। घटयति। अजीघटत्। **ज्ञप** ज्ञाने ज्ञापने च। ज्ञपयति। अजिज्ञपत्॥ **रभेरशब्लिटोः** ।७।१।६३। नुमचि॥ **लभेश्च**[1] ।७।१।६४। अररम्भत्। अललम्भत्। ईर्ष्ययति। **(ईर्ष्यतेस्तृतीयस्येति वक्तव्यम्)** तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः। आद्ये षस्य द्वित्वं वारयितुमिदम्। द्वितीये त्वजादेर्द्वितीयस्येत्यस्यापवादतया सन्नन्ते प्रवर्तते[3]। ऐर्ष्यियत्। द्वितीयव्याख्यायां णिजन्ताच्चङि ष एवाभ्यासे श्रूयते। हलादिःशेषात्। द्वित्वं तु द्वितीयस्यैव। तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः। ऐर्षिष्यत्॥ इति णिजन्तप्रक्रिया॥

अथ सन्नन्तप्रक्रिया॥ २॥

धातोः कर्मणः समानकर्तृकादिच्छायां वा[4] ।३।१।७। इषिकर्मणो धातोरिषिणैककर्तृकात्सन्वेच्छायाम्॥ **पठ** व्यक्तायां वाचि। इट्॥ **सन्यङोः** ।६।१।९। सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम्। गमनेनेच्छति इति करणान्माभूत्। समानकर्तृकात् किम्। शिष्याः पठन्त्वितीच्छति गुरुः। वाग्रहणाद्वाक्यमपि। शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥ १॥ तेन पिपठिषितुमिच्छतीति वाक्यमेव। 'लुङ्सनोर्घस्लृ'॥ **सःस्यार्धधातुके** ।७।४।४९। सस्य तः स्यात्सादावार्धधातुके। अत्तुमिच्छति जिघत्सति। एकाच इति नेट्॥ **अज्झनगमां सनि** ।६।४।१६। अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥ **इको झल्** ।१।२।१०। इगन्ताज्झलादिः सन्कित्। कर्तुमिच्छति चिकीर्षति। जिघांसति॥ **सनि च** ।२।४।४७। इणो गमिः स्यात्सनि न तु बोधने। जिगमिषति। बोधने तु प्रतीषिषति॥ **इङश्च** ।२।४।४८। गमिः सनि। अधिजिगांसते॥ **रुदविदमुषग्रहिस्वपिप्रच्छः संश्च** ।१।२।८। एभ्यः सन् क्त्वा च कितौ स्तः। रुरुदिषति। विविदिषति। मुमुषिषति॥ **सनि ग्रहगुहोश्च** ।७।२।१२।

---

१ लभेश्चेत्यत्र योगविभाग आङो यीत्यत्र लभेरेवानुवृत्तिर्यथा स्यादिति। २ तृतीयस्यैकाच इति पक्षे। ३ वचनसामर्थ्यादिति भावः। ४ इच्छायामिति श्रुतत्वात्कर्मत्वं कर्तृत्वं च तदपेक्षमेव गृह्यत इति भावः।

[1]ग्रहेर्गुहेरुगन्ताच्च सन इण्न । जिघृक्ष[2]ति ॥ **हलन्ताच्च** ।१।२।१०। इक्समीपाद्धलः परो झलादिः सन्कित् । **गुहू** संवरणे जुघुक्षति । सुषुप्सति ॥ **किरश्च पञ्चभ्यः** ।२।७।७५। कृ गृ दृ धृङ् प्रच्छ एभ्यः सन इट् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अत्रेटो दीर्घो नेष्टः ॥ **पूर्ववत्सनः** १।३।६२। सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । दिदरिषते । दिधरिषते । बुभूषति ॥ **सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्** ।६।२।४९। इवन्तेभ्य ऋधादिभ्यश्च सन इड् वा ॥ **च्छ्वोः शूडनुनासिके च** ।६।४।१९। सतुक्कस्य छस्य वस्य च क्रमात् श ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ क्ङिति च । यण् । द्वित्वम् । दुद्यूषति । दिदेविषति ॥ **स्तौतिण्योरेव षण्यभ्यासात्** ।८।३।६१। अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः षभूते सनि नान्यस्य । तुष्टूषति । सिषाधयिषति । स्तौतिण्योः किम् । सुस्यूषति । सिसेविषति ॥ **आप्ज्ञप्यृधामीत्** ।७।४।५७। एषामच ईत्स्यात्सादौ सनि[4]॥ **अत्र लोपोऽभ्यासस्य** ।७।४।५६। सनिमीमेत्यारभ्य यदुक्तं तत्राभ्यासलोपः । आप्तुमिच्छति ईप्सति । अर्दितुमिच्छति ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥ **दम्भ इच्च** ।६।४।५६। दम्भेरच इत्स्यादीच्च सादौ सनि । हलन्तादित्यत्र हल्ग्रहणं जातिपरम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्येत्युत्वम् । सुस्वूर्षति । सिस्वरिषति । युयूषति । यियविषति । 'विभाषोर्णोः' इति ङित् । ऊर्णुनुविषति । ऊर्णुनविषति । ऊर्णुनू[3]षति । बिभरिषति । बुभूर्षति । जिज्ञपयिषति । ज्ञीप्सति । सिसनिषति । सिषासति ॥ **(आशङ्कायां सन्वक्तव्यः)** । श्वा मुमूर्षति ॥ **(तनिपतिदरिद्रा-**

---

१ ग्रहेर्नित्यं गुहेर्विकल्पेन प्राप्ते निषेधोऽयम् । २ केचित्तु ढत्वे सति भष्भाव इत्यध्याहारेण योजयन्ति । तथाच जगृह स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्तं तस्यासिद्धत्वाड्ढत्वे भष्भावः । ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः । ३ इडभावे अज्झनगमामिति दीर्घः । इट्पक्षे तु विभाषोर्णोः इति वा ङित्त्वम् । ४ एकश्वविषया मरणाशङ्केति बोधः । मरणाशङ्काविषयो भवतीत्यन्ये ।

तिभ्यः सनो वेड् वाच्यः) । तितनिषति ॥ **तनोतेर्विभाषा** ।६।४।१। उपधाया दीर्घो झलादौ सनि । तितांसति । तितंसति । कूलं पिपतिषति ॥ **सनिमीमाघुरभलभशकपतपदामच इस्** ।७।४।५४। सादौ सनि । अभ्यासलोपः । पित्सति । दिदरिद्रिषति । दिदरिद्रासति ॥ **मुचोऽकर्मकस्य गुणो वा** ।७।४।५७। सादौ सनि[1]। अभ्यासलोपः । मुमुक्षते मोक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ॥ **इट् सनि वा** ।७।२।४१। वृङ्वृञ्भ्यामृदन्ताच्च सन इड् वा । विवरिषते । विवरीषते । वुवूर्षते । विवरिषति । तितरिषति । तितरीषति । तितीर्षति ॥ **स्मिपूङ्रञ्ज्वशां सनि** ।७।२।७४। स्मिङ् पूङ् ऋ अञ्जू अश् एभ्यः सन इट् । सिस्मयिषते । पिपविषते । अरिरिषति । अञ्जिजिषति । अशिशिषति ॥ **गुप** गोपने ॥ **तिज** निशाने ॥ **कित** निवासे रोगापनयने च ॥ **मान** पूजायाम् ॥ **बध** बन्धने ॥ **दान** खण्डने ॥ **शान** तेजने ॥ **गुप्तिज्किद्भ्यः सन्** ।३।१।५। **मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य** ।३।१।६। सूत्रद्वयोक्तेभ्यः सन् मानादीनामभ्यासस्येकारस्य दीर्घश्च । गुपेर्निन्दायाम् । तिजेः क्षमायाम् । कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च । मानेर्जिज्ञासायाम् । बधेश्चित्तविकारे । दानेरार्जवे । शानेर्निशाने । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवाऽनुदात्तेतः । दानशानौ तु स्वरितेतौ । एष्वर्थेष्वेते नित्यसन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्पदव्यवस्था । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेड्गुणौ न । जुगुप्सते । तितिक्षते । चिकित्सति । मीमांसते । बीभत्सते । दीदांसति । दीदांसते । शीशांसति । शीशांसते । णिचि तु । गोपयति । गोपयते । इति सन्नन्तप्रक्रिया ॥

अथ यङन्तप्रक्रिया ॥ ३ ॥

धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।३।१।२२। पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् ॥ **गुणो यङ्लुकोः** ।७।४।८२। अभ्यासस्य । ङिदन्तत्वादात्मनेपदम् । पुनःपुनरतिशयेन वा भवति । बोभूयते । बोभू-

---

१ केवले ह्यचरितं लिङ्गं समुदायोपकारकं भवति ।

यांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिरित्यादि । एकाचः किम् । पुनःपुनर्जागर्ति । हलादेः किम् । भृशमीक्षते ॥ **नित्यं कौटिल्ये गतौ ।३।१।२३।** गत्यर्थात्कौटिल्ये एव यङ् न तु क्रियासमभिहारे ॥ **दीर्घोऽकितः ।७।४।८३।** अकितोऽभ्यासस्य दीर्घो यङ्लुकोः । कुटिलं व्रजति वाव्रज्यते ॥ **यस्य हलः ।६।४।४९।** हलः परस्य यस्य लोपः स्यादार्धधातुके । 'आदेः परस्य' । 'अतो लोपः' । वाव्रजांचक्रे । वाव्रजिता ॥ **रीङ् ऋतः ।७।४।२७।** अकृद्यकारे असार्वधातुकयकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः ॥ **डुकृञ् करणे ।** चेक्रीयते ॥ **रीगृदुपधस्य च ।७।४।९०।** धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः । वरीवृत्यते । वरीवृतांचक्रे । वरीवृतिता । 'क्षुभ्नादिषु च' । नरीनृत्यते । जरीगृह्यते ॥ **(रीगृत्वत इति वाच्यम्)** । वरीवृश्च्यते ॥ **लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् ।३।१।२४।** एभ्यो धात्वर्थगर्हायामेव यङ् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥ **चरफलोश्च ।७।४।८७।** अनयोरभ्यासस्यातो नुक् यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते । स च पदान्तवद्वाच्यः । वा पदान्तस्येति यथा स्यात् ॥ **उत्परस्यातः ।७।४।८८।** चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्लुकोः । हलिचेति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥ **जपजभदहदशभञ्जपशां च ।७।४।८६।** एषामभ्यासस्य नुक् यङ्लुकोः । गर्हितं जपति । जञ्जप्ये । इत्यादि ॥ **ग्रो यङि ।८।२।२०।** गिरते रेफस्य लत्वं यङि । गर्हितं गिलति । जेगिल्यते ॥ **(सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः)** । सोसूच्यते ॥ **अट पट** गतौ । अटाट्यते ॥ **यङि च ।७।४।३०।** अर्तेः संयोगादेश्च ऋदन्ताङ्गस्य गुणो यङि । यकारपरस्य रेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशाश्यते । ऊर्णोनूयते ॥ **सिचो यङि ८।३।११२।** सस्य षो न । निसेसिच्यते ॥ **न कव-**

---

१ क्रियासमभिहार इत्युक्तत्वाद्धातोरेव स्यान्नतु प्रातिपदिकादिति पृच्छति–धातोःकिमिति । २ रुदिति किम् । चेकीर्त्यते । णिजभावपक्षे एकाच्त्वाद्यङ् । ३ अत्राभ्यासस्य सकारस्य उपसर्गात्सुनोतीति ततः परस्य तु स्यादिष्वभ्यासेन चेति षत्वे प्राप्ते निषेधोऽयम् ।

तेर्यङि ।७।४।६३। अभ्यासस्य चुत्वं न । कोकूयते । कौतिकुवत्योस्तु । चोकूयते ॥ **(हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः)** । जेघ्नीयते । हिंसायां किम् ॥ **नुगतोऽनुनासिकान्तस्य** ।७।४।८५। अदन्ताभ्यासस्य नुक् यङ्लुकोः । जंघन्यते ॥ **अयङ् यि क्ङिति** ।७।४।२२। शीङः । शाशय्यते[1] ॥ **स्वपिस्यमिव्येञां यङि** ।६।१।१९। संप्रसारणम् । सोषुप्यते । सेसिम्यते[2] । वेवीयते[3] ॥ **न वशः** ।६।१।२०। संप्रसारणम् । वावश्यते ॥ **चायः की** ।६।१।२१। चेकीयते ॥ **ई घ्राध्मोः** ।७।४।३१। जेघ्रीयते । देध्मीयते ॥ **नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्** ।७।४।८४। एषामभ्यासस्य नीग्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । वनीवच्यते । सनीस्रस्यते । दनीध्वस्यते । बनीभ्रस्यते । चनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते ॥

इति यङन्तप्रक्रिया ।

अथ यङ्लुगन्तप्रक्रिया ॥ ४ ॥

यङोऽचि च ।२।४।७४। यङोऽचि प्रत्यये लुक् स्यात् । चकारात्तं विनापि क्वचित् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । 'शेषात्कर्तरि परस्मैपदम्' । चर्करीतं चेत्यदादौ पाठाच्छपो लुक् ॥ **यङो वा** ।७।३।९४। यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड् वा स्यात् । भूसुवोरिति निषेधो यङ्लुकि भाषायां न । 'बोभूतु तेतिक्ते' इति छन्दसि निपातनात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवीषि । बोभोषि । बोभूथः । बोभूथ । बोभवीमि । बोभोमि । बोभूवः । बोभूमः । बोभवांचकार । बोभवांबभूव । बोभवामास । बोभविता । बोभविष्यति । बोभवीतु । बोभोतु । बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभूयास्ताम् । गातिस्थेति सिचो लुक् । यङो वे-

---

१ परत्वादन्तरङ्गत्वाच्चायङादेशे कृते द्वित्वम् । २ स्मशुशब्दे दन्त्याजन्तसादित्वाभावेनाषोपदेशत्वान्न षः । ३ 'हलः' इति 'अकृत्सार्व—' इति वा दीर्घः ।

तीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अबोभूवुः । अबोभविष्यत् । जङ्गमीति । जङ्गन्ति । अनुदात्तेत्यनुनासिकलोपः । जङ्गतः । जङ्ग्मति । 'म्वोश्च' जङ्गन्वः ।

शितपा शपानुबन्धेन निर्दिष्टं यद्गणेन च ।
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १ ॥

इति वचनान्न इण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि । 'मो नो धातोः' । अजङ्गमीत् । अनुबन्धनिर्देशान्न च्लेरङ् । अजङ्गमीत् ॥ **रुग्रिकौ च लुकि** ।७।४।९१। ऋदुपधस्य धातोरभ्यासस्य रुक्[2] रिक् रीक् एते स्युर्यङ्लुकि ॥ **ऋतश्च** ।७।४।९२।[3] ऋदन्तधातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः ३ । वर्वृतति ३ । वर्वर्तामास ३ वर्वर्तिता ३ । गणनिर्दिष्टत्वान्न वृद्भ्यश्चतुर्भ्य इति न । वर्वर्तिष्यति ३ । अवर्वृतीत् ३ । अवर्वर्त् ३ । सिपिदश्चेति रुत्वपक्षे रोरि । अवर्वाः ३ । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् ३ । चर्करीति । चरिकरीति । चरीकरीति । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः ३ । चर्क्रति ३ । चर्करांचकार ३ । चर्करिता ३ । अचर्करीत् ३ । अचर्कः ३ । चर्कृयात् ३ । आशिषि रिङ् । चार्क्रियात् ३ । अचर्कारीत् ३ । ऋतश्चेति तपरत्वान्नेह । चाकर्ति । चाकरीति । चाकीर्तः । चाकीर्हि । चाकराणि । अचाकरीत् । अचाकः । अचाकीर्ताम् । अचाकरुः । अचाकारीत् । अचाकारिष्टाम् । तातरीति । तातर्तीत्यादि ।

इति यङ्लुगन्ताः ॥

अथ नामधातुप्रक्रिया ॥ ५ ॥

सुप आत्मनः क्यच् ।३।१।८। इषिकर्मण एषितुरात्मसंबन्धिनः सुबन्तादिच्छायामर्थे क्यज्वा ॥ **सुपो धातुप्रातिपदिकयोः** ।२।४।७१। एतयोरवयवस्य

---

१ चकारेण 'रीगृदुपधस्य–' इत्यतो रीगनुकृष्यते । २ रुक उकार उच्चारणार्थः । ३ ऋता-ऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः । ऋदन्तधातोरिति पाठस्तु फलितार्थकथनपरतया नेयः ।

सुपो लुक् स्यात् ॥ **क्यचि च** ।७।४।३३। अवर्णस्य ईः । आत्मनः पुत्रमिच्छति पुत्रीयति ॥ **(मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच्न)** किमिच्छति । इदमिच्छति । स्वरिच्छति ॥ **अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु** ।७।४।३४। एते क्यजन्ता[1] निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥ **अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि** ।७।१।५१। एषां क्यच्यसुक् ॥ **(अश्ववृषयोर्मैथुनेच्छायाम्)** । अश्वस्यति वडवा । वृषस्यति गौः ॥ **(क्षीरलवणयोर्लालसायाम्)** । क्षीरस्यति बालः । लवणस्यत्युष्ट्रः ॥ **(सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ)** । दधिस्यति । दध्यस्यति ॥ **नः क्ये** ।१।४।१५। क्यचि क्यङि च नान्तमेव पदं नान्यत् । राजीयति[2] । नान्तमेवेति किम् । वाच्यति । 'हलि च' । गीर्यति । पूर्यति । धातोरित्येव । तेनेह न । दिवमिच्छति दिव्यति ॥ **क्यस्य विभाषा** ।६।४।५०। हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके । 'आदेः परस्य' । 'अतो लोपः' । तस्य स्थानिवद्भावान्नोपधाया गुणः । समिधिता । समिध्यिता ॥ **काम्यच्च**[3] ।३।१।८। उक्तविषये काम्यच् । पुत्रमात्मन इच्छति पुत्रकाम्यति । पुत्रकाम्यिता ॥ **उपमानादाचारे** ।३।१।१०। उपमानात्कर्मणः सुबन्तादाचारेऽर्थे[4] क्यच् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ॥ **(सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः)** । 'अतो गुणे' । कृष्ण इवाचरति । कृष्णति । स्व इवाचरति । स्वति । सस्वौ ॥ **अनुनासिकस्य क्विझलोः क्ङिति** ।६।४।१५। अनुनासिकान्तस्योपधाया दीर्घः क्वौ झलादौ क्ङिति च । इदमिवाचरति । इदामति । राजेवाचरति । राजानति । इन्हन्निति नियमान्नेहोपधाया दीर्घः । पन्था इवाचरति । पथीनति । मथीनति ॥ **कर्तुः क्यङ् सलोपश्च** ।३।१।११। उपमानात्कर्तुः सुबन्तादाचारेऽर्थे क्यङ् वा[5] सान्त-

---

१ उदकशब्दस्योदन्भावोऽन्ययोर्दीर्घत्वं चेत्यपि ज्ञेयम् । २ इह 'क्यचि च' इत्यवर्णस्येत्वे कर्तव्ये पूर्वत्रासिद्धमिति नलोपोऽसिद्धो न भवति नलोपः सुप्स्वर इति नियमात् । ३ उच्चारणसामर्थ्यान्न कस्येत्संज्ञा । ४ आचारोऽत्र व्यवहारः । ५ धातोः कर्मणः इति सूत्राद्वेत्यनुवर्तते तदाह क्यङ् वेति ।

कर्तृवाचकस्य लोपो वा । क्यङ् वेत्युक्तेः पक्षे वाक्यम् ॥ **(संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः)** । इति क्यङ्सलोपयोः सहैव प्रवृत्तिः । लोपश्च व्यवस्थितः ॥ **(ओजसोऽप्सरसोर्नित्यमितरेषां विभाषया)** । कृष्ण इवाचरति कृष्णायते । ओजायते[1] । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । **(आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः)** । वाग्रहणाद्वाक्यमपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अवगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते । तेन गल्भशब्दात्प्रागट् । अवागल्भत । अवागल्भिष्ट ॥ **लोहितादिडाज्भ्यः क्यष्** ।३।१।१३। **वा क्यषः** ।१।३।९०। क्यषन्तात्परस्मैपदं वा । अलोहितो लोहितो भवति । लोहितायति । लोहितायते । ननूच्चारणसामर्थ्यात्काम्यच इव क्यषोऽपि ककारः कुतो न श्रूयते । तस्य भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते ॥ **कष्टाय[2] क्रमणे** ३।१।१४। चतुर्थ्यन्तात्[3]कष्टशब्दादुत्साहेऽर्थे क्यङ् । कष्टाय क्रमते । कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ॥ **(सत्र[4]कक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम्)** । कण्वं[5] पापं चिकीर्षति । सत्रायते । कक्षायते ॥ **कर्मणो रोमन्थतपोभ्यां वर्तिचरोः** ।३।१।१५। कर्मीभूताभ्यां रोमन्थतपोभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति । रोमन्थायते ॥ **(हनुचलन इति वाच्यम्)** । चर्वितस्याकृष्य पुनश्चर्वणमित्यर्थः । नेह । कीटो रोमन्थं वर्तयति ॥ **(तपसः परस्मैपदं च)** । तपश्चरति । तपस्यति ॥ **बाष्पोष्मभ्यामुद्वमने** ।३।१।१६। बाष्पमुद्वमति । बाष्पायते । ऊष्मायते ॥ **(फेनाच्चेति वक्तव्यम्)** । फेनायते ॥ **शब्दवैरकलहाभ्रकण्व-**

---

१ ओजस्वीवाचरतीति विग्रहो बोध्यः । २ क्यङेवानुवर्तते स्वरितत्वात् नतु क्यष् । ३ कष्टायेति निर्देशादेव चतुर्थ्यन्तं लभ्यते । ४ सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । ५ अस्वपदविग्रहोऽत्र भवति ।

मेघेभ्यः करणे ।३।१।१७। एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् । शब्दं करोति । शब्दायते ॥ **(सुदिनदुर्दिननीहारेभ्यश्च)** । सुदिनायते । दुर्दिनायते । नीहारायते ॥ **(प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च)** । 'प्रातिपदिकाद्धात्वर्थे णिच् स्यात्' । इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौचङीत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् ॥

पुच्छभाण्डचीवराण्णिङ् ।३।१।२०। **(पुच्छादुदसने व्यसने पर्यसने च)** । विविधं विरुद्धं चोत्क्षेपणं व्यसनम् । उत्पुच्छयते । परिपुच्छयते ॥ **(भाण्डात्समाचयने)** । संभाण्डयते । समबभाण्डत ॥ **(चीवरादर्जने परिधाने च)** । संचीवरयते । भिक्षुः ॥ **मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्** ।३।१।२१। कृञर्थे[1] । मुण्डं करोति । मुण्डयति ॥ **(व्रताद्भोजनतन्निवृत्त्योः)** । पयः[2] शूद्रान्नं[3] वा व्रतयति । **(वस्त्रात्समाच्छादने)** । संवस्त्रयति ॥ **(हल्यादिभ्यो ग्रहणे)** । हलिकल्योरदन्तत्वं च निपात्यते । हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति । वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे ॥ **(सत्यार्थवेदानामापुग्वक्तव्यः)** । सत्यापयति । अर्थापयति । वेदापयति । पाशं विमुञ्चयति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायति उपवीणयति । तूलेनानुकुष्णाति अनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियाति अभिषेणयति । लोमान्यनुमार्ष्टि अनुलोमयति ॥ **त्वच संवरणे** । पचाद्यच् । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति । संवर्मयति । वर्णं गृह्णाति । वर्णयति । चूर्णैरवध्वंसते । अवचूर्णयति ॥

इति नामधातुप्रक्रिया ॥

---

१ क्वचित्क्रियासामान्ये, प्राचुर्येण तु क्रियाविशेषे । २ पयो व्रतयति । अश्नातीत्यर्थः । ३ शूद्रान्नं व्रतयति । वर्जयतीत्यर्थः । ४ उपकारं स्वीकरोतीत्यर्थः ।

अथात्मनेपदप्रक्रिया ।

कण्ड्वादिभ्यो यक् ।३।१।२७। एभ्यो धातुभ्यो[1] नित्यं यक् स्यात् स्वार्थे ॥ **कण्डूञ्** गात्रविघर्षणे । कण्डूयति । कण्डूयते । इत्यादि ॥ **कर्तरि कर्मव्यतिहारे** ।१।३।१४। क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥ **न गतिहिंसार्थेभ्यः** ।१।३।१५। व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥ (**हरतेरप्रतिषेधः**)। संप्रहरन्ते राजानः ॥ **इतरेतरान्योन्योपपदाच्च** ।१।३।१६। (**परस्परोपपदाच्चेति वक्तव्यम्**)। इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥ **नेर्विशः**[2] ।१।३।१७। निविशते ॥ **परिव्यवेभ्यः क्रियः** ।१।३।१८। परिक्रीणीते। विक्रीणीते । अवक्रीणीते । **विपराभ्यां जेः** ।१।३।१९। विजयते । पराजयते ॥ **क्रीडोऽनुसंपरिभ्यश्च** ।१।३।२१। चादाङः । अनुक्रीडते । संक्रीडते । आक्रीडते ॥ (**समोऽकूजने**)। संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥ (**आगमेः क्षमायाम्**) । ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ॥ (**शिक्षेर्जिज्ञासायाम्**)[3]। धनुषि शिक्षते । धनुर्विषयज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ **वृत्तिसर्गतायनेषु क्रमः** ।१।३।३८। वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । सर्ग उत्साहः । अध्ययनाय क्रमते । क्रमन्तेऽस्मिञ्छास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥ **आङ उद्गमने** ।१।३।४०। आक्रमते सूर्यः ॥ (**ज्योतिरुद्गमन इति वाच्यम्**)। नेह । आक्रामति धूमो हर्म्यतलात् ॥ **वेः पादविहरणे** ।१।३।४१। साधु विक्रमते वाजी ॥ **प्रोपाभ्यां समर्थाभ्याम्** ।१।३।४२। प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छ-

---

१ प्रातिपदिकव्यावृत्त्यर्थं धातुग्रहणम् । २ अर्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न । मधूनि विशन्ति भ्रमराः । इत्युक्त्वा मैथिली भर्तुरङ्के निविशती भयात् इत्यत्र तु अङ्कानि विशतीति पाठ्यम् । ३ शिक्ष विद्योपादाने इत्यस्य नेह ग्रहणम् । अनुदात्तेत्त्वादेवात्मनेपदसिद्धेः । किंतु शकेः सन्नन्तस्येति ध्वनयति— धनुर्विषय इत्यादिना ।

तीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥ **अनुपसर्गाद्वा** ।१।३।४३। क्रामति । क्रमते ॥ **अपह्नवे ज्ञः** ।१।३।४४। शतमपजानीते । अपलपतीत्यर्थः ॥ **अकर्मकाच्च** ।१।३।४५। सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्यर्थः ॥ **समवप्रविभ्यः स्थः** ।१।३।२२। संतिष्ठते । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । **(आङः प्रतिज्ञायामुपसंख्यानम्)** । शब्दं नित्यमातिष्ठते ॥ **प्रकाशनस्थेयाख्ययोश्च**[1] ।१।३।२३। गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । 'संशय्य कर्णादिषु तिष्ठते यः' कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ॥ **उदोऽनूर्ध्वकर्मणि** ।१।३।२४। मुक्तावुत्तिष्ठते । अनूर्ध्वेति किम् । पीठादुत्तिष्ठति ॥ **उपान्मन्त्रकरणे**[2] ।१।३।२५। आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन ॥ **(उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्)** । आदित्यमुपतिष्ठते । गङ्गायमुनामुपतिष्ठते । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ **(वा लिप्सायाम्)** भिक्षुकः प्रभुमुपतिष्ठति । उपतिष्ठते वा ॥ **उद्विभ्यां तपः** ।१।३।२७। अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः । **(स्वाङ्गकर्मकाच्चेति**[3] **वक्तव्यम्)** । उत्तपते वितपते पाणिम् । नेह । सुवर्णमुत्तपति ॥ **आङो यमहनः** ।१।३।२८। आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह । परस्य शिर आहन्ति ॥ **आत्मनेपदेष्वन्यतरस्याम्**[4] ।२।४।४४। हनो वधादेशो वा लुङि । आवधिष्ट । आवधिषाताम् । आवधिषत ॥ **हनः सिच्** ।१।२।१४। कित् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥ **यमो गन्धने** ।१।३।१५। सिच् कित् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥ **समो**[5]

---

१ प्रकाशनं ज्ञापनम् । स्थेयो विवादपदनिर्णेता तिष्ठतेऽस्मिन्विवादपदनिर्णयार्थमिति व्युत्पत्तेः । २ मन्त्रः करणं यत्र तन्मन्त्रकरणं स्तुतिस्तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्येति । अग्निदेवताकया ऋचा आग्नीध्रमग्निविशेषं स्तौतीत्यर्थः । ३ चकारेणाकर्मकस्य संग्रहः । ४ तङीत्येव सुवचम् । ५ 'समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः इति वृत्तिस्थं पाठमुपेक्ष्य भाष्यस्थं पाठमनुसरति समो गम्यृच्छिभ्यामिति ।

गम्यृच्छिभ्याम् ।१।२।१९। अकर्मकाभ्यामित्येव । संगच्छते ॥ **वा गमः** ।१।२।१३। गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः। संगसीष्ट । संगंसीष्ट । समगत । समगंस्त । समृच्छते । अकर्मकाभ्यां किम् । ग्रामं संगच्छति । **(विदिप्रच्छिस्वरतीनामुपसंख्यानम्)**। वेत्तेरेव[1] ग्रहणम्। संवित्ते । संविदाते ॥ **वेत्तेर्विभाषा** ।७।१।७। वेत्तेः परस्य झादेशस्यातो रुडागमो वा । संविद्रते । संविदते संपृच्छते । संस्वरते । अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् शृणु ।

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १ ॥

वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । 'हितान्न यः संशृणुते स किंप्रभुः' ॥ **संमाननोत्संजनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः**[2] ।१।३।३६। शास्त्रे नैयते[3] । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयते । कर्मकरानुपनयते । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थे विनियुङ्क्ते इत्यर्थः ॥ **(उपसर्गादस्यत्यूह्योर्वेति वाच्यम्)**। बन्धान्निरस्यति । निरस्यते । समूहति । समूहते ॥ **उपसर्गाद्ध्रस्व ऊहतेः** ।७।४।२३। यादौ किति । ब्रह्म समुह्यात् । अग्निं समुह्य ॥ **निसमुपविभ्यो ह्वः** ।१।३।३०। निह्वयते ॥ **स्पर्धायामाङः** ।१।३।३१। कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥ **उदश्चरः सकर्मकात्** ।१।३।५३। धर्ममुच्चरते । उल्लङ्घ्य गच्छ-

१ परस्मैपदिसाहचर्यादाह—वेत्तेरेवेति । विन्दतिर्हि स्वरितेत् । सत्ताविचारणार्थयोस्तु अनुदात्तेत्त्वादेव सिद्धम् । नच निरनुबन्धकपरिभाषयैव वेत्तेर्ग्रहणं स्यादिति वाच्यम् । 'लुग्विकरणालुग्विकरणयोः—' इति परिभाषया विन्दतेर्ग्रहणप्रसङ्गात् । २ अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । ३ शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितमित्यादिसर्वेषूदाहृतप्रयोगेषु नयतेरर्थाः सिद्धान्तकौमुद्यां स्पष्टमभिहिताः ।

तीत्यर्थः ॥ **समस्तृतीयायुक्तात्** ।१।३।५४। रथेन संचरते ॥ **दाणश्च सा चेच्चतुर्थ्यर्थे** ।१।३।५५। समो दाणस्तृतीयान्तेन युक्तादुक्तं स्यात्तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते कामी ॥ **उपाद्यमः स्वकरणे** ।१।३।५६। स्वकरणं स्वीकारः । भार्यामुपयच्छते ॥ **विभाषोपयमने** ।१।२।१६। यमः सिच् किद्वा विवाहेऽर्थे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः ॥ **ज्ञाश्रुस्मृदृशां सनः** ।१।३।५७। सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते दिदृक्षते ॥ **नाऽनोर्ज्ञः**।१।३।५८। पुत्रमनुजिज्ञासति ॥ **प्रोपाभ्यां युजेरयज्ञपात्रेषु**।१।३।६४। प्रयुङ्क्ते । उपयुङ्क्ते ॥ **(स्वराद्यन्तोपसर्गादिति वाच्यम्)**। उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति ॥ **समः क्ष्णुवः** ।१।३।३३। संक्ष्णुते शस्त्रम् ॥ **गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः** ।१।३।३२। गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः ॥ अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयत इत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । कथाः प्रकुरुते । प्रकथयतीत्यर्थः । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥ इत्यात्मनेपदप्रक्रिया ॥

अथ परस्मैपदप्रक्रिया ॥ ७ ॥

'शेषात्कर्तरि परस्मैपदम्' । श्वि । श्वयति ॥ **विभाषा श्वेः** ।६।१।३०। संप्रसारणं लिटि यङि च । शुशाव । शुशुवतुः ॥ **(श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः)** । शिश्वाय । शिश्वियतुः । शिश्वियुः । शूयात् । जॄस्तंभ्वित्यङ् वा ॥ **श्वयतेरः** ।७।४।१८। अङि । अश्वत् । अश्वः । विभाषेति चङ् । अशिश्वियत् । अश्वयीत् ॥ **अनुपराभ्यां कृञः** ।१।३।७९। कर्तृगे फले गन्धनादौ च परस्मैपदं स्यात् ।

---

१ ननु भार्यास्वीकारमात्रम् । अतएव भट्टिः 'उपायंस्त महास्त्राणि' इति प्रायुङ्क्त ।
२ अनुदात्तङित इत्यादिष्वात्मनेपदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः । तथाच कर्तरि परस्मैपदमित्यनेन परस्मैपदमेवेति नियमिते तद्भिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्रतिपत्त्यर्थमित्याहुः ।

अनुकरोति । पराकरोति ॥ **अभिप्रत्यतिभ्यः क्षिपः** ।१।३।८०। **क्षिप** प्रेरणे । स्वरितेत् । अभिक्षिपति ॥ **प्राद्वहः** ।१।३।८१। प्रवहति ॥ **परेर्मृषः** ।१।३।८२। परिमृष्यति ॥ **व्याङ्परिभ्यो रमः** ।१।३।८३। विरमति । आरमति ॥ **उपाच्च** ।१।३।८४। यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥ **विभाषाऽकर्मकात्** ।१।३।८५। उपाद्रमेः परस्मैपदं वा स्यात् । उपरमति । उपरमते । निवर्तत इत्यर्थः ॥ **बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः** ।१।३।८६। एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्चेत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । स्रावयति ॥ **क्रीङ्जीनां णौ** ।६।१।४८। आत्वं स्यात् । अध्यापयति ॥ **णौ च संश्चङोः** ।२।४।५१। सन्परे चङ्परे च णौ इङो गाङ् वा । अध्यजीगपत् । अध्यापिपत् । क्रापयति । जापयति ॥ **निगरणचलनार्थेभ्यश्च**[1] ।१।३।८७। निगारयति । चलयति ॥ **(अदेः प्रतिषेधः)** । आदयते देवदत्तेन ॥ **अणावकर्मकाच्चित्तवत्कर्तृकात्** ।१।३।८८। ण्यन्तात्परस्मैपदम् । शेते कृष्णस्तं गोपी शाययति ॥ **न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः** ।१।३।८९। एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ॥ **(धेट उपसंख्यानम्)** । धापयते । अकर्त्रभिप्राये शेषादिति परस्मैपदं स्यादेव । वत्सान्पाययति पयः ॥ इति परस्मैपदप्रक्रिया ॥ समाप्ता पदव्यवस्था ॥

अथ भावकर्मप्रक्रिया ॥ ८ ॥

भावकर्मणोः ।१।३।१३। लस्य तङानौ स्तः ॥ **सार्वधातुके यक्** ।१।३।६७। भावकर्मवाचिनि सार्वधातुके धातोर्यक् स्यात् । भावः क्रिया । सा च भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः । तिङ्वाच्यक्रियाया अद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादिकम्, किंतु एकव-

---

१ निगरणं भक्षणम् । २ क्रियाफलस्य कर्तृगामित्वविवक्षायामात्मनेपदे प्राप्ते परस्मैपदार्थमिदम् ।

चनमेवोत्सर्गतः। त्वया मया अन्यैश्च भूयते। बभूवे॥ **स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च** ।६।४।६२। उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षे अयमिट्। चिण्वद्भावाद्वृद्धिः। भाविता। भविता। भाविष्यते। भविष्यते। भूयताम्। अभूयत। भूयेत। भाविषीष्ट। भविषीष्ट॥ **चिण्भावकर्मणोः** ।३।१।६६। च्लेश्चिण् स्याद्भावकर्मवाचिनि ते परे। अभावि। अभाविष्यत। अकर्मकोऽप्युपसर्गवशात्सकर्मकः। अनुभूयते आनन्दश्चैत्रेण त्वया मया च। अनुभूयेते। अनुभूयन्ते। त्वमनुभूयसे। अहमनुभूये। अन्वभावि। अन्वभाविषाताम्। अन्वभविषाताम्। णिलोपः। भाव्यते। भावयांचक्रे। भावयांबभूवे। भावयामासे। चिण्वदिट्। आभीयत्वेनासिद्धत्वाण्णिलोपः। भावयिष्यते। भाविष्यते। भाव्यताम्। अभाव्यत। भाव्येत। भावयिषीष्ट। भाविषीष्ट। अभावि। अभाविषाताम्। अभावयिषाताम्। बुभूष्यते। बुभूषांचक्रे। बुभूषिता। बुभूषिष्यते। बोभूयते। अकृत्सार्वधातुकेति दीर्घः। स्तूयते विष्णुः। स्ताविता। स्तोता। स्ताविष्यते। स्तोष्यते। अस्तावि। अस्ताविषाताम्। अस्तोषाताम्। गुणोर्तीति गुणः। अर्यते। स्मर्यते। ऋच्छत्यृतामिति गुणः। आरे। सस्मरे। उपदेशग्रहणाच्चिण्वदिट्। आरिता। अर्ता। स्मारिता। स्मर्ता। नलोपः। स्रस्यते। सस्रंसे। इदितस्तु नन्द्यते। इज्यते॥ **तनोतेर्यकि** ।६।४।४४। आदन्तादेशो वा स्यात्। तायते। तन्यते॥ **तपोऽनुतापे च** ।३।१।६५। च्लेश्चिण्न कर्मकर्तरि अनुतापे च। अन्वतप्त पापेन। घुमास्थेतीत्वम्। दीयते। धीयते। ददे। दधे॥ **आतो युक् चिण्कृतोः** ।७।३।३३। आदन्तानां युगागमश्चिणि ञ्णिति कृति च। दायिता। दाता। दायिषीष्ट। दासीष्ट। अदायि। अदायिषाताम्। शम्यते मोहो मुकुन्देन॥ **चिण्णमुलोर्दीर्घोऽन्यतरस्याम्** ।६।४।९३।

---

१ च्लेः सिच् इत्यतश्च्लेरिति 'चिणते पदः' इत्यतस्ते इति चानुवर्तते। तत्रत्यं तु चिण्पदं 'न रुधः' इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम्। २ शमितेत्यादौ 'जनीजॄष्' इत्यादिना मित्त्वेन मितामुपधाया नित्यं ह्रस्वे प्राप्ते दीर्घोऽनेन विकल्प्यते।

चिण्परे णमुल्परे च णौ मितामुपधाया दीर्घो वा । शामिता । शमिता । शमयिता । शामयिष्यते । शमिष्यते । शमयिष्यते । ण्यन्तत्वाभावे शम्यते[१] मुनिना ॥ **नोदात्तोपदेशस्य मान्तस्यानाचमेः** ।७।३।३४। उपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्येति किम् । अवादि । अनाचमेरिति किम् । आचामि ॥ **(अनाचमिक्रमिवमीनामिति वक्तव्यम्)**। अकामि[२] ॥ अवामि ॥ **भञ्जेश्च चिणि** ।६।४।३३। नलोपो वा । अभाजि । अभञ्जि । लम्भ्यते ॥ **विभाषा चिण्णमुलोः** ।७।१।६९। लभेर्नुम् । अलम्भि । अलाभि ॥ इति भावकर्मप्रक्रिया ॥

अथ कर्मकर्तृप्रक्रिया ॥ ९ ॥

यदा कर्मैव[३] कर्तृत्वेन विवक्षितं तदा सकर्मकाणामपि अकर्मकत्वात्कर्तरि भावे च लः ॥ **कर्मवत्कर्मणा तुल्यक्रियः** ।३।१।८७। कार्यातिदेशोऽयम्[४] । कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत् । तेन यगात्मनेपदं चिण् चिण्वदिट् च स्युः । पच्यते फलम् । भिद्यते काष्ठम् । अपाचि अभेदि । भावे तु भिद्यते काष्ठेन ॥ **(भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वक्तव्यम्)** । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । अवाकरिष्ट । गिरते । अगीर्ष्ट । अगरिष्ट । आद्रियते । आदृत । किरादिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट ॥ **तपस्तपःकर्मकस्यैव** ।३।१।८८। कर्ता कर्मवत् । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । अतप्त । तपःकर्मकस्यैवेति किम् । उत्तपति सुवर्णं सुवर्णकारः ॥ **(सकर्मकाणां प्रतिषेधो वक्तव्यः)** । अजां ग्रामं नयति । **(दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्)** ॥ **न दुहस्नुनमां यक्चिणौ** ।३।१।८९। एषां कर्मकर्तरि यक्चिणौ न शप् । तस्य

---

१ अकर्मकत्वाद्भावे लः । २ चिणि आयादय इति णिङभावे । ३ यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । ४ यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाश्रितः ॥

लुक् । गौः पयो दुग्धे ॥ **अचः कर्मकर्तरि** ।३।१।६२। अजन्ताच्च्लेश्चिण्वा कर्मकर्तरि ते परे । अकारि । अकृत ॥ **दुहश्च** ।३।१।६३। तथा । अदोहि । अदुग्ध । लुग्वेति क्सस्य लुक्पक्षेऽयम् । अधुक्षत । उदुम्बरः फलं पच्यते ॥ **कुषिरञ्जोः प्राचां श्यन्परस्मैपदं च** ।३।१।९०। अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति । कुष्यते पादः । रज्यति । रज्यते वस्त्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥ इति कर्मकर्तृप्रक्रिया ॥

अथ लकारार्थप्रक्रिया ॥ १० ॥

अभिज्ञावचने लृट् । ३ । २ । १०२ । स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् । लङोऽपवादः ॥ **वस** निवासे । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादि प्रयोगेऽपि ॥ **न यदि** ।३।२।१०३। यद्योगे उक्तं न । अभिजानासि यद्वने अभुञ्ज्महि ॥ **विभाषा साकाङ्क्षे** ।३।२।११४। उक्तविषये लृड् वा । लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । 'परोक्षे लिट्' । चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । **(अत्यन्तापह्नवे लिड् वक्तव्यः)** । कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥ **प्रश्ने चासन्नकाले** ।३।२।११७। पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्त आसन्नकाले । अगच्छत्किम् । जगाम किम् ॥ **लट् स्मे** ।३।२।११८। लिटोऽपवादः । यजति स्म युधिष्ठिरः ॥ **अपरोक्षे च** ।३।२।११९। भूतानद्यतने लट् स्मयोगे । एवं स्म-

---

१ कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । २ तस्मिन्नेव विषय इति भावः ३ अभिज्ञा स्मृतिः सा उच्यते बोध्यतेऽनेनेति विग्रहस्तदाह—स्मृतिबोधिनीत्यादि । ४ लटः प्रतिषेधे उत्सर्गो लङ् । ५ प्रसिद्धत्वाज्ज्ञापकमित्यर्थः ॥ ६ पञ्चवर्षाभ्यन्तरमासन्नकालं पञ्चवर्षातीते विप्रकृष्टकालमित्याहुः । आसन्नकालिके भूतानद्यतनपरोक्षार्थवृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः ।

पिता ब्रवीति ॥ **ननौ पृष्टप्रतिवचने** ।३।२।१२०। भूते लट् । अकार्षीः किम् । ननु करोमि भोः ॥ **नन्वोर्विभाषा** ।३।२।१२१। अकार्षीः किम् । न करोमि । नाकार्षम् । अहं नु करोमि । अहंन्वकार्षम् ॥ **पुरि लुङ् चास्मे** ।३।२।१२२। पुरायोगे भूतानद्यतने वा लुङ् चाल्लट् न तु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे इति किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥ **यावत्पुरानिपातयोर्लट्** ।३।३।४। यावद्भुङ्क्ते[1] । पुराभुङ्क्ते । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणभूतया पुरा यास्यति ॥ **विभाषा कदाकर्ह्योः** ।३।३।५। लट् स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते भोक्ता वा ॥ **वर्तमानसामीप्ये वर्तमानवद्वा** ।३।३।१३१। वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोसि । अयमागच्छामि । आगमं वा । कदा गमिष्यसि । एष गच्छामि । एष गमिष्यामि वा । **आशंसायां[2] भूतवच्च** ।३।३।१३२। भविष्यत्काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीद्वर्षति वर्तिष्यति वा धान्यमवाप्स्म वपामः वप्स्यामो वा ॥ **क्षिप्रवचने[3] लृट्** ।३।३।१३३। क्षिप्रपर्यायोपपदे पूर्वविषये लृट् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा आयास्यति शीघ्रं वप्स्यामः ॥ **आशंसावचने[4] लिङ्** ।३।३।१३४। आशंसावाचिन्युपपदे भविष्यति लिङ् स्यात् न भूतवत् । गुरुश्चेदुपेयादाशंसे अधीयीय । **हेतुहेतुमतोर्लिङ्** ।३।३।१५६। वा स्यात् । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति । भविष्यत्येवेष्यते । नेह । हन्तीति पलायते ॥ **इच्छार्थेषु लिङ्लोटौ** ।३।३।१५७। इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये । (**कामप्रवेदन इति वक्तव्यम्**) नेह । इच्छन्करोति ॥ **लिङ् च** ।३।३।१५८। समानकर्तृकेषु इच्छार्थेषु । भुञ्जीयेतीच्छति । विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । यजेत । निमन्त्रणं नियोगकरणम् ।

---

१ निश्चितं भोक्ष्यत इत्यर्थः । २ आशंसनमाशंसा अप्राप्तस्य प्राप्तुमिच्छा । आशंसायां वर्तमानत्वेऽपि तद्विषयस्य वर्षादेर्भविष्यत्कालसंबन्धाद्भविष्यतीत्युक्तम् । ३ क्षिप्रवचने इत्यत्र वचनग्रहणं स्वरूपनिरासार्थम् तदाह—क्षिप्रपर्यायेति । ४ भूतवर्तमानवत्प्रत्यययोरपवादः ।

आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । इह भुञ्जीत । आमन्त्रणं कामचारानुज्ञा । इह आसीत । अधीष्टः सत्कारपूर्वको व्यापारः । पुत्रमध्यापयेत् । संप्रश्नः संप्रधारणम् । किं भो वेदमधीयीय उत तर्कम् । प्रार्थनं याच्ञा । भो भोजनं लभेय । एवं लोट् ॥ **प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।३।३।१६३।** प्रैषो[1] विधिः । अतिसर्गः कामचारानुज्ञा । भवता यष्टव्यम् । चाल्लोटोऽनुकर्षणं प्राप्तकालार्थम् । भवान्यजताम् ॥ **अर्हे कृत्यतृचश्च ।३।३।१६९।** चाल्लिङ् । त्वं कन्यां वहेः ॥ **शकि लिङ् च ।३।३।१७२।** शक्तौ लिङ् स्याच्चात्कृत्याः । त्वं भारं वहेः ॥ **धातुसंबन्धे प्रत्ययाः ।३।४।१।** धात्वर्थानां[2] संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङन्तवाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन्ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमित्यर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥ **क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ।३।४।२।** पौनःपुन्ये भृशार्थे च द्योत्ये[3] धातोर्लोट् तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे नानयोरतिदिश्येते हिस्वविधानसामर्थ्यात्तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥ **समुच्चयेऽन्यतरस्याम् ।३।४।३।** अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥ **यथाविध्यनुप्रयोगः पूर्वस्मिन् ।३।४।४** आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥ **समुच्चये सामान्यवचनस्य ।३।४।५।** समुच्चये लोड्विधौ सामान्यार्थस्य

---

१ प्रैषो विधिरिति विधिग्रहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः । २ विषयबहुत्वापेक्षं बहुवचनं । एकैकविषयापेक्षायां तु धात्वर्थयोरिति बोध्यम् । ३ क्रियासमभिहारो धातोरेवार्थः लोट् तु द्योतक इति भावः । ४ धातोर्लोट् लोटो हिस्वौ तध्वमोर्विषये वेत्यर्थः ।

धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्यथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ **(क्रियासमभिहारे द्वे वाच्ये)** । याहि याहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानं यानं यातीत्यस्य । इतिशब्दस्तु अभेदान्वये तात्पर्यं ग्राहयति । एवं[1] यातः । यान्ति । याथः । याथ । यातयातेति यूयं याथ । याहि याहीत्ययासीत्[2] । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वम्विषये तु पक्षे[3] अधीध्वमधीध्वमिति यूयमधीध्वे । समुच्चये सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ग्ध्वमास्वादध्वमित्यभ्यवहरध्वे । पक्षे तु हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकमास्वादते । एतेन—'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः' । इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा[4] भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहारे इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥ इति लकारार्थप्रक्रिया ॥

इति तिङन्तप्रक्रिया समाप्ता ।

---

१ एवं याहि याहीति यातः यान्तीत्येवमूह्यमित्यर्थः । २ वा च तध्वमोरित्युक्तत्वात् हिस्वाभावपक्षे इत्यर्थः । ३ विध्यादिलोड्विषये तु अधीध्वमित्येवानुप्रयोक्तव्यम् । ४ आदिशब्देन मोषणहरणे ग्राह्ये ।

अथ कृदन्तप्रकरणम् ।

धातोः ।३।१।९१। आतृतीयाध्यायान्तं ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥ **वाऽसरूपोऽस्त्रियाम्** ।३।१।९४। अस्मिन्धात्वधिकारेऽसरूपोऽपवादः प्रत्यय उत्सर्गस्य वा बाधकः स्त्र्यधिकारोक्तं विना ॥ **कृत्याः** ।३।१।९५। ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः ॥ **कर्तरि कृत्** ।३।४।६७। इति प्राप्ते ॥ **तयोरेव कृत्यक्तखलर्थाः** ।३।४।७०। एते भावकर्मणोरेव स्युः ॥ **तव्यत्तव्यानीयरः** ।३।१।९६। धातोरेते स्युः । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ॥ **केलिमर उपसंख्यानम्**)। पचेलिमा माषाः । पक्तव्या इत्यर्थः । भिदेलिमाः सरलाः । कर्मणि प्रत्ययः ॥ **(वसेस्तव्यत्कर्तरि णिच्च)** । वसतीति वास्तव्यः ॥ **कृत्यचः** ।८।४।२९। उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः ॥ **(निर्विण्णस्योपसंख्यानम्)** ॥ **णेर्विभाषा** ।८।४।३०। प्राग्वत् । प्रयापणीयम् । प्रयापनीयम् ॥ **हलश्चेजुपधात्** ।८।४।३१। हलादेरिजुपधाद्धातोः परस्य कृन्नस्याचः परस्य णो वा । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥ **इजादेः सनुमः** ।८।४।३२। सनुमश्चेद्भवति इजादेर्हलन्ताद्विहितो यः कृत्तत्स्थस्यैव ॥ **इखि गतौ** । प्रेङ्खणीयम् । इजादेः किम् ॥ **मगि सर्पणे** । प्रमङ्गनीयम् ॥ **वा निंसनिक्षनिन्दाम्** ।८।४।३३। एषां नस्य णो वा कृति । प्रणिंसितव्यम् ॥ **न भाभूपूकमिगमिप्यायीवेपाम्** ।८।४।३४। एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥ **(ण्यन्तभादीनामुपसंख्यानम्)** प्रभापनीयं ॥ **कृत्यल्युटो-**

---

१ कृतां तिङ्ज्ञानाधीनज्ञानत्वात्तिङ्निरूपणानन्तरमेव कृतां निरूपणमुचितमिति तिङो निरूप्य कृतो निरूपयितुमाह—धातोरिति । २ तृतीयाध्यायसमाप्तिपर्यन्तमिति भावः । ३ अत्रत्यौ तकाररेफौ स्वरार्थाविति ज्ञेयम् । ४ अच उत्तरस्येत्यस्य कृतो विशेषणत्वे तु प्रयापणमित्यादौ न स्यादिति भावः । ५ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वं पूर्वस्य ष्टुत्वम् ॥ ६ कृत्यच इत्येव सिद्धे नियमार्थमिदमित्याह—सनुमश्चेत्यादि ।

बहुलम् ।३।३।११३। क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ स्नात्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥ **ऋदुपधाच्चाक्लृपिचृतेः** ।३।१।११०। क्यप्स्यात् । वृत् वृत्यम् । वृध् वृध्यम् । क्लृपिचृत्योस्तु कल्प्यम् । चर्त्यम् ॥ **अचो यत्** ।३।१।९७। चेयम् । जेयम् ॥ **ईद्यति** ।६।४।६५। आतः । गुणः । देयम् । ग्लेयम् ॥ **पोरदुपधात्** ।३।१।९८। पवर्गान्ताददुपधाद्यत् । ण्यतोपवादः । शप्यम् । लभ्यम् ॥ **आङो यि** ।७।१।६५। आङः परस्य लभेर्नुम् यादौ प्रत्यये । आलम्भ्यो गौः ॥ **उपात्प्रशंसायाम्** ।७।१।६६। उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्यः उपलभ्यः ॥ **शकिसहोश्च** ।३।१।९९। शक्यम् । सह्यम् ॥ **गदमदचरयमश्चानुपसर्गे** ।३।१।१००। गद्यम् । मद्यम् । चर्यम् ॥ **(चरेराङि चागुरौ)** । आचर्यो देशः । अगुरौ किम् । आचार्यो गुरुः । यम्यम् ॥ **अवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु** ।३।१।१०१। अवद्यं पापम् । पण्यं विक्रेयम् । शतेन वर्या कन्या ॥ **वह्यं करणम्** ।३।१।१०२। वहन्त्यनेनेति वह्यं शकटम् ॥ वाह्यमन्यत् ॥ **अर्यः स्वामिवैश्ययोः** ।३।१।१०३। अनयोः किम् । आर्यो ब्राह्मणः ॥ **उपसर्या काल्या प्रजने** ।३।१।१०४। गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥ **अजर्यं संगतम्** ।३।१।१०५। विशेष्यं चेत् । न जीर्यतीत्यजर्यम् । सतां संगतम् ॥ **वदः सुपि क्यप् च** ।३।१।१०६। चाद्यत् । ब्रह्मोद्यम् । ब्रह्मवद्यम् ॥ **भुवो भावे** ।३।१।१०७। क्यप् । ब्रह्मणो भावो ब्रह्मभूयम् ॥ **हनस्त च** ।३।१।१०८। चात्क्यप् । ब्रह्मणो हननं ब्रह्महत्या ॥ **एतिस्तुशास्वृदृजुषः क्यप्** ।३।१।१०९। **ह्रस्वस्य पिति कृति तुक्** ।६।१।७१। इत्यः ।

---

१ यादौ प्रत्यये विवक्षिते उपपूर्वाल्लभेर्नुम् प्रशंसायाम् । सा चेह गम्यमानतया विशेषणम् धात्वर्थस्तु प्राप्तिरेव । २ एभ्योऽनुपसर्गेभ्यो यत्स्याण्ण्यतोऽपवादः । ३ वचिस्वपीति संप्रसारणम् ।

स्तुत्यः । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि[1] ण्यतो बाधनार्था । अवश्यस्तुत्यः । **मृजेर्विभाषा**[2] ।३।१।११३। मृजेः क्यब्वा । मृज्यः ॥ **ऋहलोर्ण्यत्** ।३।१।१२०। ऋवर्णान्ताद्धलन्ताच्च ण्यत् ॥ **चजोः कु घिण्यतोः** ।७।३।५२। चजोः कुत्वं घिति ण्यति च । (**निष्ठायामनिट इति वक्तव्यम्**) । तेनेह । गर्ज्यम् । मार्ग्यः ॥ **ओरावश्यके** ।३।१।१२२। ण्यत् । पाव्यम् । 'लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि । समो वा हिततततयोर्मांसस्य पचि युड्घञोः ॥' अवश्यलाव्यम् ॥ **भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा** ।३।४।६८। एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । भवतीति भव्यः । भव्यमनेन वा ॥ **भोज्यं भक्ष्ये** ।७।३।६९। भोग्यमन्यत्[3] ॥ **वचोऽशब्दसंज्ञायाम्** ।७।३।६७। न कुत्वम् । वाच्यम् । वाक्यमन्यत् ॥ **राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः** ।३।१।११४। एते सप्त क्यबन्ता निपात्यन्ते ॥ **भिद्योध्द्यौ नदे** ।३।१।११५। नदे किम् । भेत्ता । उज्झिता ॥ **पुष्यसिध्यौ**[4] **नक्षत्रे** ।३।१।११६। अधिकरणे क्यन्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिध्यन्त्यस्मिन्त्सिध्यः ॥ **विपूयविनीयजित्या मुञ्जकल्कहलिषु** ।३।१।११७। विपूयो मुञ्जः । विनीयः कल्कः । जित्यो हलिः ॥ **प्रत्यपिभ्यां ग्रहेः** ।३।१।११८। (**छन्दसीति वक्तव्यम्**) । प्रतिगृह्यम् । अपिगृह्यम् । लोके तु । प्रतिग्राह्यम् । अपिग्राह्यम् ॥ **पदास्वैरिबाह्यापक्ष्येषु च** ।३।१।११९। अवगृह्यम् । प्रगृह्यम् पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । ग्रामगृह्या सेना । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥ **विभाषा कृवृषोः** ।३।१।१२०। कृत्यम् । वृष्यम् । कार्यम् ।

---

१ परस्यापीति । ओरावश्यके इति प्राप्तस्य तस्यावकाशोऽवश्यलाव्यमित्यावश्यकविवक्षायां स्तुत्य इत्यादौ च क्यपोऽवकाशः । एवं अवश्यस्तुत्य इत्यादावुभयप्राप्तौ विप्रतिषेधेन परत्वात् ण्यत्स्यात् तन्माभूदिति पुनः क्यबुक्तिरिति भावः । २ ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः । ३ पालनीयमुपभोग्यं चेत्यर्थः । ४ पुष्यसिध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः । ण्यदेवेति भावः ।

वर्ष्यम् ॥ **युग्यं च पत्रे** ।३।१।१२१। पत्रं वाहनम् । योग्यमन्यत् ॥ **अमावस्यदन्यतरस्याम्** ।३।१।१२२। अमा सह वसतोऽस्यां चन्द्रार्कावित्यमावस्या अमावासा वा ॥ **अग्नौ परिचाय्योपचाय्यसमूह्याः** ।३।१।१३१। अग्नावेते साधवः ॥ **क्रतौ कुण्डपाय्यसंचाय्यौ** ।३।१।१३०। **चित्याग्निचित्ये च** ।३।१।१३२। चित्योऽग्निः । अग्नेश्चयनमग्निचित्या ॥ इति कृत्यप्रत्ययाः ॥

अथ कृत्प्रक्रिया ॥

ण्वुल्तृचौ ।३।१।१३३। धातोरेतौ स्तः । कर्तरि कृदिति कर्त्रर्थे ॥ **युवोरनाकौ** ।७।१।१। युवु एतयोरनुनासिकयोरेतौ स्तः । कारकः । कर्ता ॥ **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** ।३।१।१३४। नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच्स्यात् । नन्दयतीति नन्दनः । जनार्दनः । लवणः । गणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । पचः । आकृतिगणोऽयम् ॥ **इगुपधज्ञाप्रीकिरः कः** ।३।१।१३५। एभ्यः कः स्यात् । क्षिपः । बुधः । कृशः । ज्ञः । प्रियः । किरः ॥

---

१ अग्निरिह न ज्वलनः किंतु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं गृह्यते । २ एते साधव इति । स्थलविशेषेऽभिधेये परिपूर्वाच्चिनोतेः ण्यदायादेशश्च संपूर्वाच्च वहेस्तु संप्रसारणदीर्घौ च निपातनादिति भावः । ३ नन्दनः वामनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः । 'सहितपिदमः संज्ञायाम्' । सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविनाशनः कुलदमनः [शत्रुदमनः] **इति नन्द्यादिः** । ४ ग्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्दी । 'रक्षश्रुवपशां नौ' । निरक्षी निश्रावी निवापी निशायी । 'याचृव्याहृव्रजवदवसां प्रतिषिद्धानाम्' । अयाची अव्याहारी असंव्याहारी अव्राजी अवादी अवासी । 'अचामचित्तकर्तृकाणाम्' । अकारी अहारी अविनायी [विशायी विषाई] विशयी विषयो देशे । अभिभावी विशयी विषयो देशः । भूते । अपराधी उपरोधी परिभवी परिभावी । **इति ग्रहादिः** ।५ पच वच वप वद चल पत नदट् भषट् प्लवट् चरट् गरट् चोरट् गाहट् सूरट् देवट् [दोषट्] जर (रज) मर (मद) क्षम (क्षय) सेव मेष कोप (कोष) मेघ नर्त व्रण दर्श सर्प (दम्भ दर्प) जारभर श्वपच । **इति पचादिराकृतिगणः**।

आतश्चोपसर्गे ।६।१।१३६। प्रज्ञः । सुग्लः ॥ **पाघ्राध्माधेट्दृशः शः** ।३।१।१३७। एभ्यः शः स्यात् । पिबः । जिघ्रः । धमः । धयः । पश्यः ॥ **अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च** ।३।१।१३८। लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातयः । साहयः । अनुपसर्गात्किम् । प्रलिपः ॥ (**गवादिषु विन्देः संज्ञायाम्**) । गोविन्दः । अरविन्दम् ॥ **ददातिदधात्योर्विभाषा** ।३।१।१३९। ददः । दधः । पक्षे । वक्ष्यमाणो णः ॥ **ज्वलितिकसन्तेभ्यो णः** ।३।१।१४०। वा स्यात् । ज्वालः । ज्वलः । चालः । चलः ॥ **श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च** ।३।१।१४१। अवश्यायः । आत् । दायः । धायः । व्याधः । आस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥ **विभाषा ग्रहः** ।३।१।१४३। व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ **गेहे कः** ।३।१।१४४। गृह्णाति धान्यादिकमिति गृहम् ॥ **शिल्पिनि ष्वुन्** ।३।१।१४५। क्रियाकौशलं शिल्पम् । तद्वत्कर्तरि ष्वुन् स्यात् ॥ **षः प्रत्ययस्य** ।१।३।६। आदिरित् । नृतिखनिरञ्जिभ्य एव । नर्तकः । खनकः ॥ (**असिअकेऽने च रञ्जेर्नलोपो वाच्यः**) । रजकः ॥ **गस्थकन्** ३।१।१४६। गायतेस्थकन् । गाथकः ॥ **ण्युट् च** ।३।१।१४७। गायनः ॥ **प्रुसृल्वः समभिहारे वुन्** ।३।१।१४९। समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥ **आशिषि च** ।३।१।१५०। वुन् स्यात् । जीवतात् । जीवकः ॥ **तत्रोपपदं सप्तमीस्थम्** ।३।१।९२। सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत् कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् ॥ **कर्मण्यण्** ।३।१।११०। कर्मण्युपपदे धातोरण् । कुम्भं करोतीति कुम्भकारः ॥ **आतोऽनुपसर्गे कः** ।३।२।३। कर्मण्युपपदे आदन्ताद्धातोरनुपसर्गात्कः स्यान्नाऽण् । अणोपवादः । गोदः । कम्बलदः । अनुपसर्गे किम् । गोसंदायः ॥ (**मूलविभुजादिभ्यः कः**) । मूलानि विभुजतीति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः ॥ **सुपि स्थः** ।३।२।४। कः स्यात् ।

---

१ अप्राप्तप्रार्थनमाशीः । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः । २ अत्र सुबिति प्रत्याहारो गृह्यते न तु सप्तमीबहुवचनम् ।

समस्थः । विषमस्थः । सुपीति योगविभागादन्यस्मादपि । द्वाभ्यां पिबति इति द्विपः ॥ **अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशंकङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः** ।८।३।९७। एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः ॥ **तुन्दशोकयोः परिमृजापनुदोः** ।३।२।५। तुन्दशोकयोः कर्मणोरुपपदयो[१]राभ्यां कः ॥ **(आलस्यसुखाहरणयोरिति वक्तव्यम्)** । तुन्दपरिमृजोऽलसः । शोकापनुदः सुखस्याहर्ता ॥ **प्रे दाज्ञः** ।३।२।६। कः स्यात् । सर्वप्रदः । पथिप्रज्ञः ॥ **समि ख्यः** ।३।२।७। गोसंख्यः ॥ **गापोष्टक्** ।३।२।८। कर्मण्युपपदे । सामगः । **(पिबतेः सुराशीध्वोरिति वाच्यम्)** । सुरापी । शीधुपी ॥ **हरतेरनुद्यमनेऽच्** ।३।२।९। अंशहरः । अनुद्यमने किम् । भारहारः ॥ **(शक्तिलाङ्गलाङ्कुशतोमरयष्टिघ[२]टघटीधनुष्षु ग्रहः)** । शक्तिग्रहः ॥ **वयसि च** ।३।२।१०। उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥ **आङि ताच्छील्ये** ।३।२।११। पुष्पाण्याहरति तच्छीलः पुष्पाहरः ॥ **अर्हः** ।३।२।१२। अच् स्यात् कर्मण्युपपदे । पूजार्हा ब्राह्मणी ॥ **स्तम्बकर्णयोरमिजपोः** ।३।२।१३। **(हस्तिसूचकयोरिति वक्तव्यम्)** स्तम्बेरमो ह[३]स्ती । कर्णेजपः सूचकः ॥ **अधिकरणे शेतेः** ।३।२।१५। खे शेते खशयः ॥ **(पार्श्वादिषूपसंख्यानम्)** पार्श्वाभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरशयः ॥ **चरेष्टः** ।३।२।१६। अधिकरणे उपपदे । कु[४]रुचरः ॥ **भिक्षासेनादायेषु च** ।३।२।१७। भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः ॥ **कृञो हे[५]तुताच्छील्यानुलोम्येषु** ।३।२।२०। एषु द्योत्येषु कृञष्टः ॥ **अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य** ।८।३।४६। अत उत्तरस्यानव्ययविसर्गस्य समासे नित्यं सादेशः करोत्यादिषु ।

---

१ परिमृजापनुदोरित्यत्र पञ्चम्यर्थे षष्ठीति भावः । २ घटग्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन मद्रराज्ञीत्यत्र टच्न । ३ तत्पुरुषे कृतीति हलदन्तादिति वा ङेरलुक् । ४ कुरुषु देशेषु चरत्यटतीत्यर्थः । ५ हेतुरिह लौकिकः नतु 'तत्प्रयोजक' इत्यनेन विहितः कृत्रिमः । केवले कृञि तदसंभवात् ।

यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥ **दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु** ।३।२।२१। एषु कृञष्टोऽहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । एककरः । द्विकरः । अहस्करः । धनुष्करः । अरुष्करः ॥ **न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु** ।३।१।२३। एषु कृञष्टो न । शब्दकारः ॥ **स्तम्बशकृतोरिन्** ।३।२।२४। **(व्रीहिवत्सयोरिति वक्तव्यम्)** । स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः ॥ **हरतेर्दृतिनाथयोः पशौ** ।३।२।२५। दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशुः ॥ **फलेग्रहिरात्मंभरिश्च** ।३।२।२६। एतौ निपात्येते । चात्कुक्षिंभरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । 'ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः' इति मुरारिः ॥ **एजेः[1] खश्** ।३।२।२८। ण्यन्तात् ॥ **अरुर्द्विषदजन्तस्य मुम्** ।६।३।६७। अरुषो द्विषतोऽजन्तस्य मुम् खिदन्ते नत्वव्ययस्य । शित्वाच्छबादिः । जनमेजयतीति जनमेजयः । (वातशुनीतिलशर्द्धेष्वजधेट्तुदजहातिभ्यः खश्) । वातमजा मृगाः ॥ **खित्यनव्ययस्य** ।६।३।६६। ह्रस्वः । शुनिन्धयः । तिलंतुदः ॥ शर्द्धंजहा[2] माषाः ॥ **नासिकास्तनयोर्ध्माधेटोः** ।३।२।२९। **(स्तने धेटो नासिकायां ध्मश्चेति वक्तव्यम्)** । स्तनंधयः । टित्वात्स्तनंधयी[3] ॥ **नाडीमुष्ट्योश्च** ।३।२।३०। ध्माधेटोः खश् । नाडिंधमः । नाडिंधयः । मुष्टिंधमः । मुष्टिंधयः ॥ **उदि कूले रुजिवहोः** ।३।२।३१। कूलमुद्रुजः । कूलमुद्वहः ॥ **वहाभ्रे लिहः** ।३।२।३२। वहः स्कन्धः तं लेढीति वहंलिहो गौः । अभ्रंलिहो वायुः ॥ **परिमाणे**

---

१ एजेरिति ण्यन्तस्य निर्देशो न तु शुद्धस्यैका निर्देशः शित्करणाल्लिङ्गात् । तद्धि सार्वधातुकत्वे च सति शप् यथा स्यादिति । नच शुद्धस्य शपि सत्यसति वा विशेषोऽस्ति । नचोत्तरार्थं शित्वमिति वाच्यम् । इहार्थवत्त्वे संभवति केवलोत्तरार्थत्वस्यान्याय्यत्वात्तदेतदाह—ण्यन्तादिति । २ शर्द्धोऽपानशब्दः तं जहतीति विग्रहः । ३ अवयवे अचरितार्थत्वादिति भावः । खश्प्रत्ययान्तादेव धेटो ङीबिष्टो नान्यतः ।

पचः ।३।२।३३। प्रस्थंपचा स्थाली । खारिंपचः कटाहः ॥ **मितनखे च** ।३।२।३४। मितंपचा ब्राह्मणी । नखंपचा यवागूः ॥ **विध्वरुषोस्तुदः** ।३।२।३५। विधुंतुदः । अरुंतुदः ॥ **असूर्यललाटयोर्दृशितपोः** ।३।२।३६। असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । असूर्यंपश्या राजदाराः । ललाटंतपः सूर्यः ॥ **प्रियवशे वदः खच्** ।३।२।३८। प्रियंवदः । वशंवदः ॥ **(गमेः सुपि वाच्यः)** । [1]मितङ्गमो हस्ती ॥ **(विहायसो विह च खश्च डिद्वा वाच्यः)** । विहङ्गमः । विहङ्गः । भुजङ्गमः । भुजङ्गः ॥ **द्विषत्परयोस्तापेः** ।३।२।३९। खच् ॥ **खचि ह्रस्वः** ।६।४।९४। खचि परे णौ उपधाया ह्रस्वः । द्विषन्तं परं वा तापयति द्विषंतपः । परंतपः ॥ **वाचि यमो व्रते** ।३।२।४०। खच् ॥ **वाचंयमपुरंदरौ च** ।६।३।६२। वाक्पुरोरमन्तत्वं निपा[2]त्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥ **पूःसर्वयोर्दारिसहोः** ।३।२।४१। खच् । पुरं दारयतीति पुरंदरः । सर्वंसहः । भगं दारयतीति भगंदरः इति कथम् । बाहुलकात् ॥ **सर्वकूलाभ्रकरीषेषु कषः** ।३।२।४२। सर्वंकषः खलः । कूलंकषा नदी । अभ्रंकषो वायुः । करीषंकषा वात्या ॥ **मेघर्तिभयेषु कृञः** ।३।२।४३। मेघंकरः । ऋतिंकरः । भयंकरः । भयशब्देन तदन्तविधिः । अभयंकरः ॥ **क्षेमप्रियमद्रेऽण् च** ।३।२।४४। एषु कृञोऽण् चात्खच् । क्षेमंकरः । क्षेमकारः । प्रियंकरः । प्रियकारः । मद्रंकरः । मद्रकारः । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् । एवं गङ्गाधरभूधरादयः ॥ **आशिते भुवः करणभावयोः** ।३।२।४५। खच् । [3]आशितो भवत्यनेन । आशितंभव ओदनः । आशितस्य भवनं आशितंभवः ॥ **संज्ञायां भृतृवृजिधारिसहितपिदमः** ।३।२।४६। खच् । विश्वं बिभर्तीति विश्वंभरः । रथंतरं [4]साम । शत्रुंजयो हस्ती ।

---

१ खकारो मुमर्थश्चकारस्तु खचि ह्रस्व इति विशेषणार्थं इति । २ व्रतादन्यत्रातिप्रसङ्गभियात्र न खच् निपातितः । ३ यावता ओदनेन अतिथ्यादिर्भोजितो भवति स एवमुच्यते । ४ इह रथेन तरतीति व्युत्पत्तिमात्रं नत्ववयवार्थानुगमः । तत्फलं तु स्वरावग्रहौ 'रथंतरमाजभारा वसिष्ठः' इत्यत्र रथमित्यवगृह्णन्ति पदकाराः । कृदुत्तरपदप्रकृतिस्वरेण चान्तोदात्तत्वम् । अखण्डत्वे त्ववग्रहो न स्यात् नब्विषयस्येत्युदात्तश्च स्यात् ।

युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिन्दमः ॥ **गमश्च** ।३।२।४७। सुतंगमः ॥ **अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः** ।३।२।४८। गमेः । अन्तगः । (**सर्वत्रपन्नयोरिति वाच्यम्**) सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः ॥ (**उरसो लोपश्च**) । उरसा गच्छतीत्युरगः ॥ (**सुदुरोरधिकरणे**) । सुखेन गच्छतीत्यत्र । सुगः । दुर्गः (**अन्यत्रापि दृश्यत इति वाच्यम्**) । ग्रामगः ॥ (**डे च विहायसो विहादेशो वाच्यः**) । विहगः ॥ **आशिषि हनः** ।३।२।४९। शत्रुं वध्यात् शत्रुहः । अशिषि किम् । शत्रुघातः ॥ (**दारावाहनोणन्तस्य च टः संज्ञायाम्**) । दारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः ॥ (**चारौ वा**) चार्वाघाटः । चार्वाघातः ॥ **अपे क्लेशतमसोः** ।३।२।५०। अपपूर्वाद्धन्तेर्डः । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥ **कुमारशीर्षयोर्णिनिः**[1] ।३।२।५१। कुमारघाती । शिरसः शीर्षभावो निपात्यते । शीर्षघाती ॥ **लक्षणे जायापत्योष्टक्** ।३।२।५२। हन्तेष्टक् लक्षणवति कर्तरि । जायाघ्नो[2] ना । पतिघ्नी स्त्री ॥ **अमनुष्यकर्तृके च** ।३।२।५३। जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलम्बघ्नः कृतघ्न इत्यादि । मूलविभुजादित्वात्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुलकादण् ॥ **शक्तौ हस्तिकपाटयोः** ।३।२।५४। हन्तेष्टक् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥ **पाणिघताडघौ शिल्पिनि** ।३।२।५५। शिल्पिनि किं । पाणिघातः ॥ (**राजघ उपसंख्यानम्**) । राजानं हन्ति राजघः ॥ **आढ्यसुभगस्थूलपलितनग्नाऽन्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्** ।३।२।५६। एषु च्व्यर्थेष्व[3]च्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् । अनाढ्यमाढ्यंकुर्वन्त्यनया आढ्यंकरणी[4] । अच्वौ

---

१ एतयोः कर्मणोरुपपदयोर्हन्तेर्णिनिः स्यादिति । २ जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति सः तां हन्तीति गौणो व्यवहारः एवं पतिघ्नीत्यत्रापि बोध्यम् । ३ अभूततद्भावविषयेष्वित्यर्थः । ४ लिङ्गविशिष्टपरिभाषया आढ्याशब्देत्युपपदे यदा ख्युन् तदापि खित्यनव्ययस्येति ह्रस्वेन तदेव रूपम् ।

किम्। आढ्यीकुर्वन्त्यनेन ॥ **कर्तरि भुवः खिष्णुच् खुकञौ** ।३।२।५७। आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः। अनाढ्य आढ्यो भवति आढ्यंभविष्णुः । आढ्यंभावुकः ॥ **सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्** ।३।२।६१। एभ्यः क्विप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । द्युसत्[1]। सदिरप्रतेरिति षः । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुट् । प्रध्रुट् । गोधुट् प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निवित् ॥ (**अग्रग्रामाभ्यां नयतेर्णो वाच्यः**[2]) । अग्रणीः । ग्रामणीः ॥ **भजो ण्विः** ।३।२।६२। अंशभाक् । प्रभाक् ॥ **अदोऽनन्ने** ।३।२।६८। विट् स्यात् । आममत्तीत्यामात् । सस्यात् । अनन्ने किम् । अन्नादः । **क्रव्ये च** ।३।२।६९। अदेर्विट् । पूर्वेण सिद्धे वचनं वासरूपेति प्राप्ताणबाधनार्थम् । क्रव्यात् आममांसभक्षकः ॥ **दुहः कप् घश्च** ।३।२।७०। कामदुघा ॥ **अन्येभ्योऽपि दृश्यन्ते** ।३।२।७५। मनिन् क्विनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥ **नेड्वशि कृति** ।७।२।८। वशादेः कृत इण्न सुशर्मा[3] । प्रातरित्वा[4] ॥ **विड्वनोरनुनासिकस्यात्** ।६।४।४१। विजायत इति विजावा । **ओणृ** अपनयने । अवावा । रोट् । रेट् । सुगण् ॥ **क्विप् च** ।३।२।७६। अयमपि दृश्यते । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥ **अन्तः** ।७।४।२०। पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् ॥ (**आशासः**[5] **क्वावुपधाया इत्वं वाच्यम्**) । आशीः । इत्वोत्वे । गीः । पूः । 'मो नो धातोः' प्रतान् । प्रशान् ॥ **गमः क्वौ** ।६।४।४०। अनुनासिकलोपः । अङ्गत् ॥ (**गमादीनामिति वक्तव्यम्**) परीतत् । संयत् । (**ऊङ् च गमादीनामिति वक्तव्यम्**) ।

---

१ पूर्वपदादिति षत्वं तु न भवति छन्दसीत्यनुवृत्तेः । तथाच माघः—मनःसु येन द्युसदाभ्यधीयत' इति । 'आदितेया दिविषदः' इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः । २ 'स एषां ग्रामणीः' इति निर्देशेन ज्ञापितमेतत् । ३ सुष्ठु शृणोतीति विग्रहः । ४ प्रातः एतीति प्रातरित्वा । इणः क्वनिपि 'ह्रस्वस्य पिति' इति तुक् । ५ शासु अनुशिष्टौ, आङः शासु इच्छायाम्, अनयोरात्मनेपदे 'शास इत्—' इत्यादिना सिद्धे क्वावेवोपधाया इत्वमिति नियमार्थमिदम् । तेन आशास्ते इति सिद्धम् ।

लोपश्च । गूः । भूः ॥ **स्थः क च** ।३।२।७७। चात्क्विप् । शंस्थः शंस्थाः ॥ **सुप्यजातौ णिनिस्ताच्छील्ये** ।३।२।७८। अजात्यर्थे धातोर्णिनिस्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी ॥ **मनः** ।३।२।८२। सुपि मन्यतेर्णिनिः । दर्शनीयमानी ॥ **आत्ममाने खश्च** ।३।२।८३। स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः[1] । पाण्डितमानी । **इच एकाचोऽम्प्रत्ययवच्च** ।६।३।६८। इजन्तादेकाचोम्स्यात्स च स्वाद्यम्वत्[2] खिदन्ते परे । 'औतोऽम्शसोः' । गांमन्यः । 'वाऽम्शसोः' स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारप्रयोगाच्छ्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥ **भूते** ।३।२।८४। अधिकारोऽयं वर्तमाने लडिति यावत् ॥ **करणे यजः** ।३।२।८५। करणे उपपदे भूतार्थाद्यजेर्णिनिः कर्तरि । सोमेनेष्टवान्सोमयाजी ॥ **कर्मणि हनः** ।३।२।८६। पितृव्यघाती ॥ **ब्रह्मभ्रूणवृत्रेषु क्विप्** ।३।२।८७। ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप्चेत्येव सिद्धे ब्रह्मादिष्वेव क्विबेवति द्विविधनियमार्थमिदम् । एवमग्रेऽपि ॥ **सुकर्मपापमन्त्रपुण्येषु कृञः** ।३।२।८९। सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् ॥ **सोमे सुञः** ।३।२।९०। सोमसुत् ॥ **अग्नौ चेः** ।३।२।९१। अग्निचित्[3] ॥ **कर्मण्यग्न्याख्यायाम्** ।३।२।९२। कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप् । अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित्[4] ॥ **कर्मणीनिविक्रियः** ।३।२।९३। कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः ॥ **(कुत्सितग्रहणं कर्तव्यम्)** सोमविक्रयी । घृतविक्रयी ॥ **दृशेः क्वनिप्** ।३।२।९४। कर्मणि भूते । पारं दृष्टवान्पारदृश्वा ॥ **राजनि युधि कृञः** ।३।२।९५। क्वनिप् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् । राजयुध्वा । राजकृत्वा ॥ **सहे च** ।३।२।९६। सहयुध्वा । सहकृत्वा ॥

---

१ एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम् । २ अम्ग्रहणमिहावर्तते । ततः एकेन अम् विधीयते परेण प्रत्ययो विशेष्यते । ३ अत्र भूतकालस्य क्विपि नियतत्वादग्निचितवानग्निचाय इति अण् न । ४ समुदायोऽयमाहवनीयधारणार्थे इष्टकानिर्मितस्थलविशेषे निरूढः ।

सप्तम्यां जनेर्डः ।३।२।९७। **तत्पुरुषे कृति बहुलम्** ६।३।१४। ङेरलुक्। सरसिजम्। सरोजम्॥ **उपसर्गे च संज्ञायाम्** ।३।२।९९। प्रजाः॥ **अनौ कर्मणि** ।३।२।१००। अनुपूर्वाज्जनेः कर्मण्युपपदे डः। पुमांसमनुरुध्य जाता पुमनुजा॥ **अन्येष्वपि दृश्यते** ।३।२।१०१। अजः। द्विजः। ब्राह्मणजः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि कारकान्तरेष्वपि, क्वचित्। परितः खाता परिखा॥ **पञ्चम्यामजातौ** ।३।२।९८। जातिशब्दवर्जिते पञ्चम्यन्ते जनेर्डः। संस्कारजः। अदृष्टजः॥ **क्तक्तवतू निष्ठा** ।१।१।२६। एतौ निष्ठासंज्ञौ ः॥ **निष्ठा** ।३।२।१०२। भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान्॥ **अदो जग्धिर्ल्यप्ति किति** ।२।४।३६। ल्यपि तादौ किति च। इकार उच्चारणार्थः। जग्धम्॥ **निष्ठायामण्यदर्थे** ।६।४।६०। ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात्॥ **क्षियो दीर्घात्** ।८।२।४६। निष्ठातस्य नः। क्षीणवान्। भावकर्मणोस्तु क्षितः कामो मया॥ **(ऊर्णोतेर्णुवद्भावो वाच्यः)** तेन एकाच्त्वान्नेट्। ऊर्णुतः॥ **रदाभ्यां निष्ठातो नः पूर्वस्य च दः** ।८।२।४२। रदाभ्यां परस्य निष्ठातस्य नो निष्ठापेक्षया पूर्वस्य धातोर्दस्य च। शॄ। शीर्णः। भिन्नः। छिन्नः॥ **संयोगादेरातो धातोर्यण्वतः** ।८।२।४३। यण्वत्संयोगादेरादन्तान्निष्ठातस्य नः। द्राणः। ग्लानः॥ **ल्वादिभ्यः** ।८।२।४४। एकविंशतेर्लूनादिभ्यः प्राग्वत्। लूनः। ज्या। ग्रहिज्या॥ **हलः** ।६।४।२। अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्याङ्गस्य दीर्घः। जीनः॥ **(दुग्वोर्दीर्घश्च)** दु गतौ। दूनः॥ **गु पुरीषोत्सर्गे**। गूनः॥ **(पूञो विनाशे)**। पूना यवाः। विनष्टा इत्यर्थः। पूतमन्यत्॥ **(सिनोतेर्ग्रासकर्मकर्तृकस्य)** सिनो ग्रासः।

---

१ यद्यपि याज्या ऋगित्यादौ करणादावपि बाहुलकाण्यद्भवति तथापि 'तयोरेव—' इति वचनाद्भावकर्मणी एव साक्षादुपात्तोर्थे इति स एवेह विवक्षित इति भावः। २ 'क्षि क्षये' 'क्षयो निवासे' इति द्वयोरपि ग्रहणम्। ३ ग्रासरूपं कर्म ग्रासकर्म तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः। ४ पिण्डीक्रियमाणो ग्रासो यदा दध्यादिव्यञ्जनवशाद्बन्धनेऽनुकूलो भवति तदा कर्मण एव कर्तृत्वमिति बोध्यम्।

ग्रासेति किम्। सिता पाशेन सूकरी। कर्मकर्तृकेति किम्। सितो ग्रासो देवदत्तेन॥ **ओदितश्च** ।८।२।४५। प्राग्वत्। भुजो, भुग्नः। टु ओश्वि, शूनः॥ **द्रवमूर्तिस्पर्शयोः श्यः** ।६।१।२४। द्रव्यस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम्॥ **श्योऽस्पर्शे** ।८।२।४७। श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे। शीनं घृतम्। अस्पर्शे किम्। शीतं जलम्। द्रवमूर्तिस्पर्शयोरिति किम्। संश्यानो वृश्चिकः। शीतात्संकुचित इत्यर्थः॥ **प्रतेश्च** ।६।१।२५। संप्रसारणं निष्ठायाम्। प्रतिशीनः॥ **विभाषाभ्यवपूर्वस्य** ।६।१।२६। तथा। अभिश्यानं घृतम्। अभिशीनम्। अवश्यानः अवशीनो वृश्चिकः। व्यवस्थितविभाषेयम्। तेनेह न। समवश्यानः॥ **अञ्चोऽनपादाने** ।८।२।४८। निष्ठातस्य नः॥ **यस्य[1] विभाषा** ।७।२।१५। यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठायामिण् न। उदितो वेति क्त्वायां वेट्त्वादिह नेट्। समक्तः। अनपादाने किम्। उदक्तमुदकं कूपात्॥ **दिवोऽविजिगीषायाम्** ।८।२।४९। द्यूनः। विजिगीषायां तु द्यूतम्॥ **निर्वाणोऽवाते** ।८।२।५०। अवाते इति च्छेदः। निपूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातश्चेत्[3]कर्ता न। निर्वाणोऽग्निर्मुनिर्वा। वाते तु निर्वातो वातः॥ **शुषः कः** ।८।२।५१। निष्ठातस्य कः। शुष्कः॥ **पचो वः** ।८।२।५२। पक्वः॥ **क्षायो मः** ।८।२।५३। क्षामः॥ **स्त्यः प्रपूर्वस्य** ।६।१।५३। प्रात्स्त्यः संप्रसारणं निष्ठायाम्॥ **प्रस्त्योऽन्यतरस्याम्** ।८।२।५४। निष्ठातस्य मो वा। प्रस्तीमः। प्रस्तीतः। प्रात्किम्। स्त्यानः॥ **अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः** ।८।२।५५। एते निपात्यन्ते। ञिफला, फुल्लः। निष्ठातस्य लत्वं निपात्यते। क्तवत्वेकदेशस्यापीदं निपातनमिष्यते। फुल्लवान्। अनुपसर्गात्किम्॥ **आदितश्च** ।७।२।५६। आकारेतो निष्ठाया इण्न। **ति च** ।७।२।८९। चरफलोरत उत् तादौ किति। प्रफुल्तः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाघितः॥ **(उत्फुल्लसंफुल्लयोरुपसंख्यानम्।) [4]रुदविदोन्दत्राघ्राह्री-**

१ यस्येत्यार्धधातुकापेक्षया षष्ठी। यदीयस्यार्धधातुकस्येत्यर्थः। २ 'विजिगीषया हि तत्राक्षाः पात्यन्त इति गम्यते विजिगीषा। ३ एवं च वातेन हेतुना निर्वाणो दीप इत्यत्र निषेधो नेत्याहुः। ४ 'रदाभ्यां' 'संयोगादेरातो—'इति नित्ये प्राप्ते ह्री इत्यस्याप्राप्ते उभयत्रविभाषेयम्।

भ्योऽन्यतरस्याम् ।८।२।५६। निष्ठातस्य नः । नुन्नः । नुत्तः । विन्नः । वित्तः । उन्दी ॥ **श्वीदितो निष्ठायाम्** ।७।२।१४। श्वयतेरीदितश्च निष्ठाया इण् न । उन्नः । उत्तः । इत्यादि ॥ **न ध्याख्यापॄमूर्छिमदाम्** ।८।२।५७। एभ्यो निष्ठातस्य नो न । ध्यातः । ख्यातः । पूर्तः ॥ **राल्लोपः** ।६।४।२१। राच्छ्वोर्लोपः स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । मूर्तः । मत्तः ॥ **वित्तो भोगप्रत्यययोः** ।८।२।५८। विन्दतेर्निष्ठान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तः पुरुषः । अनयोः किम् । विन्नः ॥ **भित्तं शकलम्** ।८।२।५९। भिन्नमन्यत् ॥ **ऋणमाधमर्ण्ये**[1] ।८।२।६०। ऋतमन्यत् ॥ **स्फायः स्फी निष्ठायाम्** ।६।१।२२। स्फीतः ॥ **इण्निष्ठायाम्** ।७।२।४७। निरः कुषो निष्ठाया इट् । यस्य विभाषेति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥ **वसतिक्षुधोरिट्** ।७।२।५२। आभ्यां क्त्वानिष्ठयोर्नित्यमिट् । उषितः । क्षुधितः ॥ **अञ्चेः पूजायाम्** ।७।२।५३। क्त्वानिष्ठयोरिट् । अञ्चितः । गतौ तु अक्तः ॥ **लुभोऽविमोहने** ।७।२।५४। क्त्वानिष्ठयोरिट् नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥ **क्लिशः क्त्वानिष्ठयोः** ।७।२।५०। इट् वा । क्लिशितः । क्लिष्टः ॥ **पूङश्च** ।७।२।५१। क्त्वानिष्ठयोरिड् वा ॥ **पूङः क्त्वा च** ।१।२।२२। निष्ठा सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधादित्यत्र हि क्त्वैव संबध्यते ॥ **निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः** ।१।२।१९। सेट् किन्न । शयितः ॥ **(आदिकर्मणि निष्ठा वक्तव्या)**[2] **आदिकर्मणि क्तः कर्तरि च** ।३।४।७०। चाद्भावकर्मणोः ॥ **विभाषा भावादिकर्मणोः** ।७।२।१७। आदितो निष्ठाया इड् वा । प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । ञिष्विदेति भ्वादिरत्र गृह्यते । ञिद्भिः साहचर्यात् । स्विद्यतेस्तु स्विदित इत्येव । ञिमिदा ञिक्ष्विदा

---

१ अधमं दुःखप्रदमृणं यस्य सोऽधमर्णः । तस्य भाव आधमर्ण्यं तेन व्यवहारविशेषो लक्ष्यते । स व्यवहारो दातृग्रहीत्रोः संबन्धो भवतीत्युत्तमर्णेऽपि प्रयोगो न विरुध्यते । लक्षणायां तु धारेरुत्तमर्ण इति निर्देशो लिङ्गम् । २ आद्येषु क्षणेषु सर्वस्याः क्रियाया भूतत्वाभावान्निष्ठा न प्राप्नोतीति वचनम् । आदिकर्मणि क्तस्य कर्तरि विधानार्थं चेत्याहुः । तक्रकौण्डिन्यन्यायेन भावकर्मणोर्बाधो मा भूदिति चकारः ।

दिवादी भ्वादी च । प्रमेदितः । प्रक्ष्वेदितः । प्रधर्षितः । धर्षितं तेन । सेट् किम् । प्रस्विन्नः । प्रस्विन्नं तेनेत्यादि ॥ **मृषस्तितिक्षायाम्** ।१।२।२०। सेण् निष्ठा किन्न । मर्षितः । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥ **उदुपधाद्भावादिकर्मणोरन्यतरस्याम्** ।१।२।२१। उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्योतितः । प्रद्युतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट् किम् । क्रुष्टम् । शब्विकरणेभ्य एवेष्यते । नेह गुध्यते-गुधितम् ॥ **निष्ठायां सेटि** ।६।४।५२। णेर्लोपः । भावितः । भावितवान् ॥ **दृढः स्थूलबलयोः**[1] ।७।२।२०। स्थूले बलवति च निपात्यते ॥ **दधातेर्हिः**[2] ।७।४।४२। तादौ किति । हितम् ॥ **दो दद्धोः**[3] ।७।४।४६। घुसंज्ञस्य दा इत्यस्य दथ् तादौ किति । चर्त्वम् । दत्तः ॥ **गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च** ।३।४।७२। एभ्यः कर्तरि क्तः स्याद्भावकर्मणोश्च । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः ॥ **द्यतिस्यतिमास्थामित्ति किति** ।७।४।४०। एषामित्तादौ किति । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा तेनेत्यादि ॥ **क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः** ।३।४।७६। एभ्योऽधिकरणे क्तः चाद्यथाप्राप्तम् ॥ मुकुन्दस्यासितमिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ १ ॥ पक्षे आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन ॥ **(गत्यर्थेभ्यः कर्तरि कर्मणि च)** रमापतिरिदं यातः । तेनेदं यातम् । भुजेः कर्मणि । अनन्तेनेदं भुक्तम् । वर्तमाने इत्यधि-

---

१ बलमस्यास्तीति बलः अर्शआदित्वादच् तदाह—बलवतीति । स्थूलो मांसलः । स च निर्बलोऽपि बलवान् कृशोऽपि दृढ इति फलितोऽर्थः । २ शितपानिर्देशो धेटो निवृत्त्यर्थः । ३ इहादेशस्यान्त एव न तु तदधान्तः । जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियाया दोषात् । तान्ते-दीर्घत्वाख्यो दोषः । दान्ते निष्ठानत्वम् । धान्ते दोषो धत्वाख्यः । निर्दोषत्वात्थान्तो ग्राह्य इति भावः ।

कृत्य ॥ **ञीतः क्तः** ।३।२।१८७। ञिष्विदा ॥ **मतिबुद्धिपूजार्थेभ्यश्च** ।३।२।१८८। राज्ञां मतः । इष्टः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः। शीलितः । रक्षितः । क्षान्तः । आक्रुष्टो जुष्ट इत्यादि ॥ **नपुंसके भावे क्तः** ।३।३।११४। क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः । जल्पितं । हसितम् ॥ **सुयजोर्ङ्वनिप्** ।३।२।१०३। भूते । सुत्वा । यज्वा ॥ **जीर्यतेरतृन्** ।३।२।१०४। जरन् । जरन्तौ । वासरूपन्यायेन निष्ठापि । जीर्णः । जीर्णवान् ॥ **छन्दसि लिट्** ।३।२।१०५। **लिटः कानज्वा** ।३।२।१०६। **क्वसुश्च** ।३।२।१०७। भूतसामान्ये छन्दसि लिट् । तस्य कानच्क्वसू वा स्तः । 'तङानावात्मनेपदम्' । चक्राणः । 'म्वोश्च' । जगन्वान् । कवयस्तु बाहुलकाल्लोकेऽपि प्रयुञ्जते । 'तं तस्थिवासं नगरोपकण्ठे' 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि ॥ **वस्वेकाजाद्घसाम्** ।७।२।६७। कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वासोरिट् स्यान्नान्येषाम् । आदिवान् । आरिवान् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥ **भाषायां सदवसश्रुवः** ।३।२।१०८। सदादिभ्यो भूतसामान्ये भाषायां लिड् वा स्यात् तस्य च नित्यं क्वसुः । 'निषेदुषीमासनबन्धधीरः' 'अध्यूषुषस्तामभवज्जनस्य' । शुश्रुवान् ॥ **उपेयिवाननाश्वाननूचानश्च** ।३।२।१०९। एते निपात्यन्ते । उपादिणो लिड् वा तस्य क्वसुः । इट् । उपेयिवान् । नात्रोपसर्गस्तन्त्रम् । ईयिवान् । नञोऽश्नातेः क्वसोरिडभावश्च । अनाश्वान् । अनोर्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥ **लटः शतृशानचावप्रथमासमानाधिकरणे** ।३।२।१२४। अप्रथमान्तेन सामानाधिकरण्ये लट एतौ वा स्तः । शबादिः । पचन्तं चैत्रं पश्य ॥ **आने मुक्** ।७।२।८२। अङ्गस्यातः । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने

---

१ मतिरिहेच्छा बुद्धेः पृथगुपादानात् । २ 'तीषसहे'ति वेट्कत्वाद्यस्य विभाषेति नेट् । ३ षुञ् अभिषवे । यद्यपीह सु गतौ षुप्रसवैश्वर्ययोरिति निरनुबन्धकग्रहणं न्याय्यं तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोर्ग्रहणं न । ४ यद्यप्यादेशरहितस्य लटः प्रयोगाभावात्सामानाधिकरण्यं दुर्लभं तथापि शतृशानचोस्तद्दृष्ट्वा स्थानिन्यपि सामानाधिकरण्यं कल्प्यते । ५ विच्छित्त्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः ।

पुनर्लड्ग्रहणात्प्रथमासामानाधिकरण्येऽपि क्वचित् । सन्द्विजः ॥ **ईदासः ।७।२।८३।** आनस्य । 'आदेः परस्य' । आसीनः ॥ **विदेः शतुर्वसुः ।७।१।३६।** वेत्तेः परस्य शतुर्वसुरादेशो वा । विद्वान् । विदन् ॥ **तौ सत् ।३।२।१२७।** तौ शतृशानचौ सत्संज्ञौ स्तः ॥ **लृटः सद्वा ।३।३।१४।** करिष्यन्तं करिष्यमाणं पश्य ॥ **ताच्छील्यवयोवचनशक्तिषु चानश् ।३।२।१२९।** अग्नौ जुह्वानः । कवचं बिभ्राणः । शत्रुं निघ्नानः ॥ **आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ।३।२।१३४।** क्विपमभिव्याप्य वक्ष्यमाणास्तच्छीलादिषु कर्तृषु बोध्याः ॥ **तृन् ।३।२।१३५।** कर्ता कटान् ॥ **स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ।३।२।१५८।** आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः ॥ (शीङो वाच्यः) शयालुः ॥ **अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ।३।२।१३६।** अलंकरिष्णुः ॥ **ग्लाजिस्थश्च ग्स्नुः ।३।२।१३९।** गिदयं नतु कित् । तेन स्थ ईत्वं न । ग्लास्नुः । गित्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्युकः कितीत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥ **त्रसिगृधिधृषिक्षिपेः क्नुः ।३।२।१४०।** त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥ **शमित्यष्टाभ्यो घिनुण् ।३।२।१४१।** उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शिमिनीतरेत्यत्र उगितश्चेति ह्रस्वविकल्पः । नचैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात् । नोदात्तोपदेशस्येति वृद्धिनिषेधः । शमी । तमीत्यादि ॥ **संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ।३।२।१४२।** घिनुण् स्यात् । संपर्कीत्यादि ॥ **वौ कषलसकत्थस्रम्भः ।३।२।१४३।** विकाषी ॥ **अपे च लषः ।३।२।१४४।** चाद्वौ । अपलाषी । विलाषी ॥ **चलनशब्दार्थादकर्मकाद्युच् ।३।२।१४८।** चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चेलनः ।

---

१ चानशो लादेशत्वाभावेनात्मनेपदत्वाभावात्परस्मैपदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति । २ चल कम्पने ।

चोपनः[1] । कम्पनः[2] । शब्दनः[3] । रवणः[4] । अकर्मकात्किम् । पठिता विद्या । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥ **निन्दहिंसक्लिशखादविनाश[5]परिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् ।३।२।१४६।** एभ्यो वुञ् । निन्दकः । हिंसक इत्यादि ॥ **देविक्रुशोश्चोपसर्गे ।३।२।१४७।** आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥ **लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।३।२।१५४।** लाषुकः । पातुकः ॥ **जल्पभिक्षकुट्टलुण्टवृङः षाकन् ।३।२।१५५।** जल्पाकः ॥ **सनाऽऽशंसभिक्ष उः ।३।२।१६८।** चिकीर्षुः । आशंसुः । भिक्षुः ॥ **स्थेशभासपिसकसो वरच् ।३।२।१७५।** स्थावरः । इत्यादि ॥ **यश्च यङः ।३।२।१७६।** यातेर्यङन्ताद्वरच् । अतोलोपः । तस्याचः परस्मिन्निति स्थानिवद्भावे प्राप्ते ॥ **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ।१।१।५८।** पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति यलोपं प्रति स्थानित्वनिषेधाल्लोपो व्योर्वलीति यलोपः । अल्लोपस्य स्थानिवत्त्वमाश्रित्याल्लोपे प्राप्ते ॥ **(वरे लुप्तं न स्थानिवत्)** यायावरः ॥ **भ्राज[6]भासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।३।२।१७७।** विभ्राट् । भाः । धूः । विद्युत् । ऊर्क् । पूः । दृशिग्रहणस्यापकर्षणाज्जवतेर्दीर्घः । जूः । ग्रावस्तुत् ॥ **(क्विब्वचि[8]प्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च)** वक्तीति वाक् । पृच्छतीति प्राक् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं श्रीः[9] ॥ **(ध्यायतेः संप्रसारणं च)** । धीः ॥ **दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।३।२।१८२।** दाबादेः ष्ट्रन् करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥ **तितुत्रतथसिसुसरकसेषु**

---

१ चुप मन्दायां गतौ । २ कपि संचलने । ३ शब्द शब्दने चुरादिः । ४ रु शब्दे । 'युवोः–' इत्यनादेशः । ५ इह सूत्रे विनाशेति विपूर्वस्य नशेः ण्यन्तस्य भाविना णिलोपेन निर्देशः । अकारस्त्वागन्तुकः । ६ आक्रेरित्युक्तत्वात्तच्छीलादिष्वयं क्विप् । ७ औणादिकमिदं सूत्रम् । ८ अत्र दीर्घः संप्रसारणाभावश्च । प्राप्तिस्तु 'वचिस्वपि, ग्रहिज्या–' इत्यादिना । ९ प्राचा तु श्रयन्त्येतामिति कर्मणि क्विबुदाहृतस्तत्र कर्तरि कृदिति सूत्रविरोधः स्पष्ट एव ।

च ।७।२।९। एषां दशानां कृत्प्रत्ययानामिण्न । शास्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम्[1] । पत्रम् । दंष्ट्रा । नद्ध्री[2] ॥ **हलसूकरयोः पुवः ।३।२।१८३।** पूङ्पूञोः करणे ष्ट्रन् । तच्चेत्करणं[3] हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रं मुखमित्यर्थः ॥ **अर्तिलूधूसूखनसहचर इत्रः ।३।२।१८४।** अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥ **पुवः संज्ञायाम् ।३।२।१८५।** पवित्रम् ॥

अथोणादयः ।

कृवापाजिमिस्वदिसाध्यशूभ्य उण् । करोतीति कारुः । वायुः । पायुर्गुदम् । जायुरौषधम् । मायुः पित्तम् । स्वादुः । साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥ **हरिमितयोर्द्रुवः** । द्रु गतौ । अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवतीति मितद्रुः समुद्रः ॥ **शते च** । शतधा द्रवतीति शतद्रुर्नदीभेदः ॥ **अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः** । एते कूप्रत्ययान्ता निपात्यन्ते ॥ **शमेर्ढः** । बाहुलकात् इत्संज्ञा ढस्य एयादेश इट् च न भवति । 'शण्ढः स्यात्पुंसि गोपतौ' ॥ **कमेरठः** । 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी ॥ **रमेर्वृद्धिः** ॥ रामठं हिङ्गु ॥ **शमेः खः** ॥ शङ्खः ॥ **कणेष्ठः** । कण्ठः । **अमन्ताड्डः** । अमिति प्रत्याहारः । 'दण्डोऽस्त्री लगुडेऽपि' स्यात् इत्यमरः । 'रण्डा मूषिकपर्ण्यां च विधवायां च योषिति' इति मेदिनी । 'खण्डोऽस्त्री नेक्षुविकारमणिभेदयोः' इति मेदिनी । मन ज्ञाने । 'मण्डः पञ्चाङ्गुले शङ्कुभेदे क्लीबं तु वस्तुनि' । इति मेदिनी ॥ **पतिचण्डिभ्यामालच्** । 'पातालं नागलोके स्याद्विवरे वडवानले' इति मेदिनी । चण्डालो मातङ्गः । प्रज्ञादित्वादणि चाण्डालोऽपीत्युज्ज्वलदत्तः । तन्न । 'कुलालवरुडकर्मारनिषादचण्डालमित्राऽमित्रेभ्यश्छन्दसि' इति चण्डालशब्दात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरोधात् ॥ **गन्गम्यद्योः** । गङ्गा । अङ्गः[5] ।

---

१ ह्रो ढः धत्वष्टुत्वढलोपाः । २ 'नहो धः' इति धत्वम् । ३ एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्तम् । ४ तत्रैव रूढिरिति भावः । ५ धू विधूनने इति कुटादिरेव गृह्यते निरनुबन्धकत्वात् । अत एव 'गाङ्कुटा'—इति ङित्वाद्गुणनिषेधे उवङ् ।

पुरोडाशः । **भृञः किन् नुट् च** । भृञो गन्कित्स्यात्तस्य नुट् च । 'भृङ्गाः षिट्गाऽलिधूम्याटाः' । **शृणातेर्ह्रस्वश्च** । शृङ्गम् । **अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिणीभ्यो मन्** । एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः । सोमः । होमः । सर्मो गमनम् । धर्मः । क्षेम कुशलम् । क्षौमम् । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष्मो रोगराजः । नेमः । **अवतेष्टिलोपश्च** । मन्प्रत्ययस्यायं टिलोपो नतु प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् ॥ **ज्वरत्वरस्रिव्यविमवामुपधायाश्च** ।६।४।२०। एषामुपधावकारयोरूठ् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुन्नि कृते ओतुरिति दर्शनात् । स्वरादिपाठादव्ययत्वम् । अवतीति आम् । **ग्रसेरा च** । ग्रासः । **अविसिविशुषिभ्यः कित्** । एभ्यो मन् । ऊमं नगरं । स्यूमो रश्मिः । सिमः सर्वः शुष्ममग्निसमीपयोः । घर्मः । घृ धातोर्निपातोऽयम् । ग्रीष्मः । ग्रसतेर्निपातोऽयम् ॥ **अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्** । अश्वः । 'पुष्पः स्याद्दतुसूर्ययोः' । लट्वः पक्षिभेदः फलं च । कण्वं पापम् । खट्वा । विश्वम् । **कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः** । यौतीति युवा । वृषा इन्द्रः । तक्षा राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यत्यस्मिन्प्रतिदिवा दिवसः । **उषिकुषिगार्तिभ्यः स्थन्** । ओष्ठः । कोष्ठः । गाथा । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । **पातृतुदिवचिरिचिसिचिभ्यस्थक्** । 'पीथो रविर्घृतं पीथं' । तीर्थं शास्त्राऽध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम्' इति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकाद्दचेरपि । 'रिक्थमृक्थं धनं वसु' सिक्थम् । **ग्लानुदिभ्यां डौः** । ग्लौः । नौः । **च्विरयम्** । डौरित्येव । ग्लौकरोति । 'कृन्मेजन्तः' इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति । **गमेर्डोः** । 'गौर्नाऽऽदित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ तु सुरभावपि ॥ नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु' इति । बाहुलकात् द्युतेरपि डोः । 'द्यौः स्त्रीस्वर्गान्तरिक्षयोः' ॥ **रातेर्डैः** । राः । **भ्रमेश्च डूः** । भ्रूः । चाद्गमेः । अग्रे गूः । **उन्देर्नलोपश्च** । चाद्युच् । ओदनः । **गमेर्गश्च** । चाद्युच् ।

गगनम्। **कॄपॄवृजिमन्दिनिधाञः क्युः** । किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रं । निधनं कुलनाशयोः । **घृषेर्धिष च संज्ञायाम्** । धिषणो गुरुः । धिषणा धीः । **तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायाम्** । शंसादिभ्यः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तस्तौ चाऽनिटौ । शंस्ता । शंस्तारौ । शंस्तरः । क्षदिः सौत्रो धातुः । 'क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे' । **बहुलमन्यत्रापि** । मन् मन्ता । हन् हन्ता । इत्यादि । **नप्तृ नेष्टृ त्वष्टृ होतृ पोतृ भ्रातृ जामातृ मातृ पितृ दुहितृ** । एते तृजन्ता निपात्यन्ते । नप्ता । इत्यादि । **सावसेर्ऋन्**। स्वसा । **यतेर्वृद्धिश्च** । 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' । **नञि च नन्देः** । न नन्दतीति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके । 'ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सा' इति शब्दार्णवः । **दिवेर्ऋः** । देवा । देवरः । 'स्वामिनो देवृदेवरौ' । **नयतेर्डिच्च** । ना । नरौ । **अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः** ॥ 'अर्चिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः' । हविः सर्पिः । **इस्मन्त्रन्क्विषु च** ।३।४।९७। छर्दिः ह्रस्वः स्यात् । छदिः पटलं । छर्दिः । **बृंहेर्नलोपश्च** । 'बर्हिर्ना कुशशुष्मणोः' । **द्युतेरिसिन्नादेश्च जः** । ज्योतिः । **जनेरुसिः** । 'जनुर्जननजन्मानि' इत्यमरः ॥ **अर्तिपृवपियजितनिधनितपिभ्यो नित्** । अरुः । परुर्ग्रन्थिः । यजुः । तनुषी । धनुः । धनुरस्त्रियाम् । 'तपुः सूर्याग्निशत्रुषु' । **एतेर्णिच्च** । आयुः । आयुषी । **चक्षेः शिच्च** । चक्षुः । **मुहेः किच्च** । मुहुः । पुनः अव्ययम् । **पानीविषिभ्यः पः** । रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । वेष्पः पानीयम् । **स्तुवो दीर्घश्च** । स्तूपः समुच्छ्रायः । **सुशृभ्यां निच्च** । चात्कित् । सूपः । बाहुबलकादूत्वम् । शूर्पः । **कुयुभ्यां च** । कुवन्ति मण्डूका अस्मिन्निति कूपः । युवन्ति बध्नन्ति अस्मिन्निति यूपः । **खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः** । सप्तैते पप्रत्ययान्ता निपात्यन्ते । **स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्** । अयामन्तेति णेरय् । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नुः । गदयित्नुः । मदयित्नुः । मदिरा । **अशेः सरः** । अक्षरम् । **वसेश्च** । वत्सरः । **संपूर्वाच्च** । संवत्सरः । **परिवत्सरः** । **कृशृशलिकलिगर्दिभ्यो-**

ऽभच् । करभः । शरभः । शलभः । कलभः करिशावकः । गर्दभः । **ऋषिवृषिभ्यां कित्** । ऋषभः । वृषभः । **रासिवल्लिभ्यां च** । रासभः । वल्लभः । **नियो मिः** । नेमिः । **अर्तेरुच्च** । ऊर्मिः । **भुवः कित्** । भूमिः । **अङ्गेर्निर्नलोपश्च** । अग्निः । **वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्** । वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । **पातेर्डतिः** । पतिः । **सूङः क्रिः** । सूरिः । **अदिशदिभूशुभिभ्यः क्रिन्** । अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिः । ब्रह्मा । **वलिमलितनिभ्यः कयन्** । वलयः । मलयः । तनयः ॥ **माछाससिभ्यो यः** । माया । छाया । सस्यं । बाहुलकात्सव्यं दक्षिणवामयोः । **जनेर्यक्** । 'ये विभाषा' । जन्यं युद्धम् । जाया । **सर्वधातुभ्य इन्** । पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । काशत इति काशिः । पतिः । मल्लिः । केलिः । 'मसी परिणामे' । मसिः । बोधिः । नन्दिः । कलिः ॥ 'हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवंगे च यमे वाते च कीर्तितः' इति । **इगुपधात्कित्** । ऋषिः । शुचिः । **मनेरुच्च**[1] । अतः । मुनिः । **जनिघसिभ्यामिण्** । जनिर्जननम् । घासिर्भक्ष्यमग्निश्च । **अच इः** । रविः । तरिः । पविः । कविः । अविः । **कुण्डिकम्प्योर्नलोपश्च** । कुडिः । कपिः । **इषेः क्सुः** । इक्षुः । **कृषेर्वर्णे** । नक् स्यात् । कृष्णः । **दाभाभ्यां नुः** । दानुः दाता । भानुः । **विषेः किच्च** । विष्णुः । **सितनिजनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्** । सेतुः । तन्तुः । जन्तुः । गन्तुः । मस्तुर्दधिमण्डम् । सक्तुः । ओतुः । धातुः । क्रोष्टा । **अवितृस्तृतन्त्रिभ्य ईः** । अवीर्नारी रजस्वला । तरीः । स्तरीः । तन्त्रीः । **यापोः किद्द्वे च** । ययीः । 'पपीः स्यात्सोमसूर्ययोः' । **वातप्रमीः** । निपातोऽयम् । **लक्षेर्मुट् च** । लक्ष्मीः । **सर्वधातुभ्यो मनिन्** । कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम । **बृंहेर्नोच्च** । नकारस्य अकारः । 'ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः' । **नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन्** ।

---

१ मन ज्ञानेऽस्मादिन् स्यात्स च कित् । अकारस्योकारादेशश्च । मन्यते जानातीति मुनिः । 'मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी ।

सप्तैते निपात्यन्ते । **साऽतिभ्यां मनिन्मनिणौ** । साम आत्मा । **हनिमषिभ्यां सिकन्** । 'हंसिका हंसयोषिति' । मक्षिका । **गिरे[1] उडच्** । गरुडः । **शॄदॄभसोऽदिः** । शरत् । शरद्धृदयकूलयोः । भसज्जघनम् । **त्यजितनियजिभ्यो डित्** । त्यद् तद् यद् । **एतेस्तुट् च** । एतद् । **युष्यसिभ्यां मदिक्** । त्वम् । अहम् । **इन्देः कमिन्नलोपश्च** । इदम् । **कायतेर्डिमिः** । किम् । **सर्वधातुभ्यः[2] ष्ट्रन्** । वस्त्रम् । अस्त्रम् । शास्त्रम् । **अमिचिमिदिशसिभ्यः क्त्रः** । अन्त्रम् । चित्रम् । मित्रम् । शस्त्रम् । **पुवो ह्रस्वः** । पुत्रः । **स्त्यायतेर्ड्रट्[3]** । स्त्री । **सूचेः स्मन्** । सूक्ष्मम् । **पातेर्डुम्सुन्** । पुमान् । **बसेस्तिः** । 'बस्तिर्नाभेरधो द्वयोः' । **स्वावसेः** । स्वस्ति । **वौ तसेः** । 'वितस्तिर्द्वादशाङ्गुलः' इत्यमरः । **सर्वधातुभ्योऽसुन्** । चेतः । सरः । पयः । पयसी इत्यादि । **अशेर्देवने युट् च** । देवने स्तुतौ । यशः । **उब्जेर्बले बलोपश्च** । ओजः । **श्रयतेः स्वाङ्गे शिरः किच्च** । श्रयतेः शिर आदेशोऽसुन्किच्च । शिरः । **अर्तेरुच्च** । उरः । **भूरञ्जिभ्यां कित्** । भुवः । रजः । **वसेर्णिच्च** । वासो वस्त्रम् । **चन्देरादेश्च छः[4]** । छन्दः । **पचिवचिभ्यां सुट् च** । 'पक्षसी तु स्मृतौ पक्षौ' । वक्षः । **नञि हन एह च** । अनेहा । अनेहसौ । **विधाञो वेध च** । वेधाः । **चन्द्रे मो डित्** । चन्द्रोपपदान्माङोऽसिः स च डित् । चन्द्रमाः । **उषः कित्** । उषः अप्सराः । **सर्तेरप्पूर्वादसिः** । प्रायेणाऽयं भूम्नि । अप्सरसः । **वसेः कनसिः** । उशना । **अदिभुवो[5] डुतच्** । अद्भुतम् । **गुधेरूमः** । गोधूमः[6] ।

---

१ गॄ निगरणे । केचित्तु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्य डीङो डप्रत्यये पृषोदरादित्वाद्गरुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति । २ दशपाद्यां तु अर्थात् सर्वधातुभ्यो भविष्यतीत्याशयेन ष्ट्रन्नित्येव सूत्रितम् । अत एवाधिकं प्रक्षिप्तमित्याहुः । ३ ष्ट्यैस्त्यै शब्दसंघातयोः । डित्वाट्टिलोपः । लोपो व्योरिति यलोपः । टित्त्वान्ङीप् । ४ चदि आह्लादे । अस्मादसुन् आदेश्छकारश्च । 'छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः' इति मेदिनी । अकारान्तोऽप्ययम् । 'छन्दावभिप्रायवशौ' इत्यमरद्विरूपकोशौ । ५ अदित्यव्ययम् । आकस्मिकार्थेऽस्मिन्नुपपदे भूधातोर्डुतच् । डित्वाट्टिलोपः । अद्भुतमाश्चर्यम् । ६ गुध परिवेष्टने गुध्यते परिवेष्ट्यते प्राणिभिरिति विग्रहः ।

तृहेः क्नो हलोपश्च । तृणम् । **उदि चेर्डैसिः** । उच्चैः । **नौ दीर्घश्च** । नीचैः । **पूञो यण्णुग्घ्रस्वश्च** । यत्प्रत्ययः । पुण्यम् । **उदिद्दणातेरजजौ पूर्वपदान्त्यलोपश्च** । उदरम् । **डित्खनेर्मुट् चोदात्तः** । **अजल् च डिद्धातोर्मुट्** । मुखम् । **अमेः सन्** । असः । **मुहेः खो मूर्च** । मूर्खः । **नहेर्हलोपश्च** । नखः । **शीङो ह्रस्वश्च** । शिखा । **माङ ऊखो मय च** । मयूखः । **जनेष्टन्नलोपश्च** । जटा । **क्लिशेरन् ललोपश्च** । केशः । **फलेरितजादेश्च पः** । पलितम् । **कृञादिभ्यः संज्ञायां वुन्** । करकः । कटकः । नरकः । 'नरको नारकोऽपि च' इति द्विरूपकोशः । **चीकयतेराद्यन्तविपर्ययश्च** । कीचकः ॥ **जनेररष्ठ च** । जठरम् । **हर्यतेः कन्यन् हिर च** । हिरण्यम् । **कृञः पासः** । कर्पासः । बिल्वादित्वात्कार्पासम् । **ऊर्णोतेर्डः** । ऊर्णा । **दधातेर्यन् नुट् च** । धान्यम् ॥ **चतेरुरन्** । चत्वारः । **प्राततेररन्** । प्रातः । **अमेस्तुट् च** । अन्तः । **दहेर्गो लोपो दश्च नः** । दहेर्गप्रत्ययो धातोरन्तस्य लोपो दस्य नः नगः । **हन्तेरच् घुरच्** । घोरम् । **तरतेर्ड्रिः** । त्रयः । **ग्रहेरगिः** । ग्रहणिः । **प्रथेरमच्** । प्रथमः । **चरेश्च** । चरमः । **मङ्गेरलच्** । मङ्गलम् । इत्युणादिः ॥

अथोत्तरकृदन्तम् ।

उणादयो बहुलम् ।३।३।१। एते वर्तमाने संज्ञायां बहुलं स्युः । केचिदविहितो अप्यूह्याः । "संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु" । **दाशगोघ्नौ संप्रदाने** ।३।४।७३। एतौ निपात्येते । दाशन्ति अस्मै दाशः । गां हन्ति अस्मै गोघ्नः अतिथिः । **तुमुण्ण्वुलौ क्रियायां क्रियार्थायाम्** ।३।३।१०। क्रियार्थायां क्रियायामुपपदे भविष्यदर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । **कालसमयवेला-**

---

१ 'वर्तमाने लट्' इत्यतो वर्तमानग्रहणं पुवःसंज्ञायामित्यतः संज्ञाग्रहणं चानुवर्तते । २ हतेरुलज्विहितः स तु शङ्केरपि भवति शङ्कुलेति प्रयोगदर्शनात् । ३ अनादिसंज्ञास्वेव नतु सर्वास्वित्यर्थः । हतेरुलच्प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते । ४ क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था । ५ कृष्णकर्मकभविष्यद्दर्शनकर्तृकं दर्शनप्रयोजनकं यानमित्यर्थः ।

सु तुमुन् ।३।३।१६७। कालः समयो वेला वा भोक्तुम् ॥ **भावे** ।३।३।१८। सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् । पाकः ॥ **अकर्तरि च कारके संज्ञायाम्** ।३।३।१९। कर्तृभिन्ने कारके घञ् ॥ **घञि च भावकरणयोः** ।६।४।२७। रञ्जेर्नलोपः । रागः । अनयोः किम् । रज्यत्यस्मिन्निति रङ्गः ॥ **निवासचितिशरीरोपसमाधानेष्वादेश्च कः** ।३।४।४१। एषु चिनोतेर्घञादेश्च कः । उपसमाधानं राशीकरणम् । निकायः । आकायः[1] । कायः । गोमयनिकायः ॥ **एरच्** ।३।३।५६। इवर्णान्तादच् । चयः ॥ **ऋदोरप्** ।३।३।५७। ऋदन्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः । घञर्थे कविधानम् । प्रस्थः । विघ्नः ॥ **ड्वितः क्त्रिः** ।३।३।८८। भावे स्वभावात् ॥ **क्त्रेर्मम् नित्यम्** ।४।४।२०। क्त्रिप्रत्ययान्तान्मप्निर्वृत्तेऽर्थे । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् । उप्त्रिमम् ॥ **ट्वितोऽथुच्** ।३।३।८९। अयमपि भावे । **टुवेपृ** कम्पने । वेपथुः । श्वयथुः । **यजयाचयतविच्छप्रच्छरक्षो नङ्**[2] ।३।३।९०। यज्ञः । याच्ञा । यत्नः । विश्नः[3] । प्रश्नः । रक्ष्णः ॥ **स्वपो नन्** ।३।३।९१। स्वप्नः ॥ **उपसर्गे घोः किः** ।३।३।९२। प्रधिः । उपाधिः ॥ **स्त्रियां क्तिन्** ।३।३।९४। स्त्रीलिङ्गे भावादौ क्तिन् । घञोऽपवादः । कृतिः । स्तुतिः । (**ऋल्वादिभ्यः क्तिन्निष्ठावद्वक्तव्यः**) । तेन नत्वम् । कीर्णिः । गीर्णिः । धूनिः । लूनिः । पूनिः ॥ (**संपदादिभ्यः क्विप्**) सम्पत् । विपत् । आपत् । क्तिन्नपीष्यते । संपत्तिः । विपत्तिः । आपत्तिः ॥ **ऊतियूतिजूतिसातिहेतिकीर्तयश्च** ।३।३।९७। एते निपात्याः ॥ **कृञः** ।३।३।९९। क्यप् । कृत्या ॥ **श च** ।३।३।१००। कृञः शः । चात् क्तिन् । प्रकरणम् । प्रक्रिया[4] । कृतिः ॥ **इच्छा** ।३।३।१०१। इषेर्निपातोऽयम् ॥ **अ प्रत्ययात्** ।३।३।१०२। प्रत्य-

---

१ आचीयन्तेऽस्मिन्निष्टका इत्याकायः । अधिकरणे घञ् । अग्निस्थलविशेषस्य संज्ञा । २ भावेऽकर्तरिकारके चेति वर्तते । अत एव 'यज्ञेन यज्ञमयजन्त देवाः' इत्यत्र इज्यते यज्ञ इति व्याचक्षते । ३ 'छ्वोः शूडनुनासिके च' इति शः । ४ यदा भावकर्मणोः शः तदा 'सार्वधातुके यक्' 'रिङ्शयग्लिङ्क्षु' इति रिङादेशः । अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम् ।

यान्तेभ्यः स्त्रियामकारप्रत्ययः । चिकीर्षा । पुत्रकाम्या ॥ **गुरोश्च हलः** ।३।३।१०३। गुरुमतो हलन्तात्स्त्रियामप्रत्ययः । ईहा । ऊहा ॥ **षिद्भिदादिभ्योऽङ्** ।३।३। १०४। जॄष् 'ऋदृशोऽङि गुणः' । जरा । त्रपूष् त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा । (**कृपेः संप्रसारणं च**) । कृपा ॥ **आतश्चोपसर्गे** ।३।३।१०६। अङ् स्यात् । उपदा । अन्तर्द्धा ॥ **ण्यासश्रन्थो युच्** ।३।३।१०७। अस्यापवादः । कारणा ॥ **रोगाख्यायां ण्वुल् बहुलम्** ।३।३।१०८। प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः । (**धात्वर्थनिर्देशे ण्वुल्वक्तव्यः**) आशिका । (**इक्श्तिपौ धातुनिर्देशे**) । पचिः । पचतिः । (**वर्णात्कारः**) निर्देश इत्येव । अकारः । ककारः । (**रादिफः**) । रेफः ॥ **नपुंसके भावे क्तः** ।३।३।११४। **ल्युट् च** ।३।३।११५। हसितम् । हसनम् ॥ **करणाधिकरणयोश्च** ।३।३।११७। ल्युट् । अनुमानः । अनुमानी ॥ **पुंसि संज्ञायां घः प्रायेण** ।३।३।११८। **छादेर्घेऽद्व्युपसर्गस्य** ।३।४।९६। द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे । दन्तच्छन्दः । आकुर्वन्त्यस्मिन्नित्याकरः । **अवेतॄस्त्रोर्घञ्** ।३।३।१२०। अवतारः । अवस्तारो जवनिका ॥ **हलश्च** ।३।३।१२१। हलन्ताद्घञ् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिकमित्यपामार्गः ॥ **ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्** ।३।३।१२६। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च । कृच्छ्रे दुष्करः कटो भवता । अकृच्छ्रे ईषत्करः । सुकरः ॥ **आतो युच्** ।३।३।१२८। खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥ **आवश्यकाधमर्ण्ययोर्णिनिः** ।३।३।१७०। अवश्यंकारी । शतंदायी ॥ **कृत्याश्च** ।३।३।१७१। तथा धातोः । अवश्यं सेव्यो हरिः । शतं देयम् ॥ **क्तिच् क्तौ च संज्ञायाम्** ।३।३।१७४। आशिषि । वातिर्वायुः । शिवो देयादेनं शिवदत्तः ॥ **अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा** ।३।४।१८।

---

१ कथं तर्हि 'मुखाब्जगन्धलब्धेः' इति माघः 'प्रेक्षोपलब्धिः' इत्यमरश्च । पित्वादङि लभेत्येव ह्युचितम् । सत्यम् । अनर्थकास्तु प्रतिवर्णमनुपलब्धेरिति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः । २ 'न लोका' इति षष्ठीनिषेधात् कर्तरि तृतीया ।

प्राचामिति पूजार्थम्। प्रतिषेधयोरलंखल्वोरुपपदयोः क्त्वा। 'दो दद् घोः'। अलं दत्त्वा। 'घुमास्थे'तीत्वम्। पीत्वा खलु। अलंखल्वोः किम्। माकार्षीः। प्रतिषेधयोः किम्। अलंकारः॥ **समानकर्तृकयोः पूर्वकाले** ।३।२।२१। समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा। 'अव्ययकृतो भावे'। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। स्नात्वा भुक्त्वा पीत्वा व्रजति॥ **न क्त्वा सेट्** ।१।२।१८। सेट् क्त्वा किन्न। शयित्वा। सेट् किम्। कृत्वा॥ **रलो व्युपधाद्धलादेः संश्च** ।१।२।२६। इवर्णोवर्णोपधाद्धलादेरलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा। द्योतित्वा। लिखित्वा। लेखित्वा। व्युपधात्किम्। वर्तित्वा। रलः किम्। सेवित्वा। हलादेः किम्। एषित्वा। सेट् किम्। भुक्त्वा॥ **उदितो वा** ।७।२।५६। उदितः परस्य क्त्व इड् वा। शमित्वा। शान्त्वा। देवित्वा। 'छ्वोः शूडनुनासिके चे'ति ऊठ्। द्यूत्वा। दधातेर्हिः। हित्वा॥ **जहातेश्च क्त्वि** ।७।४।४३। हित्वा। हाङस्तु हात्वा॥ **समासेऽनञ्पूर्वे क्त्वो ल्यप्** ।७।१।३७। अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः तुक्। प्रकृत्य। अनञ् किम्। अकृत्वा। अव्ययपूर्वपदात्किम्। परमकृत्वा॥ **वा ल्यपि** ।६।४।३८। अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपः। स च व्यवस्थितः। **(मान्तानिटां वा)**। **(नान्तानिटां नित्यम्)**। आगम्य। आगत्य। प्रहत्य। अदो जग्धिः। प्रजग्ध्य॥ **न ल्यपि** ।६।४।६९। घुमास्थेतीत्वम्। प्रदाय। प्रमायेत्यादि॥ **आभीक्ष्ण्ये णमुल् च** ।३।४।२२। पौनःपुन्ये द्योत्ये क्त्वाविषये णमुल् क्त्वा च॥ **नित्यवीप्सयोः** ।८।१।४। आभीक्ष्ण्ये वीप्सायां च द्योत्ये परस्य द्वित्वं स्यात्। आभीक्ष्ण्ये तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च पचति पचति। स्मारं स्मारं नमति गुरुम्। स्मृत्वा स्मृत्वा। पायम् २। भोजम् २। श्रावम् २॥ **अन्यथैवंकथमित्थंसुसिद्धाप्रयोगश्चेत्** ।३।४।२७।

---

१ ननु विकल्पार्थमेवास्तु अलं रुदित्वा अलं रोदनेनेति प्रयोगद्वयसिद्ध्यर्थमिति चेन्मैवम्। वासरूपन्यायेनैतत्सिद्धेः। नच 'क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति' इति सिद्धान्तात् ल्युटि वासरूपन्यायो नास्तीति वाच्यम्। क्तल्युडादयोऽपवादभूताः स्वबाध्यं नित्यं बाधन्ते इति हि तस्यार्थः। लुटोऽपवादः क्त्वा इति वैषम्यात्।

एषु कृञो णमुल्स्यात् सिद्धोऽप्रयोगोऽस्य एवंभूतश्चेत्कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् एवंकारम् कथंकारम् । इत्थंकारं भुङ्क्ते । इत्थं भुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथाकृत्वा भुङ्क्ते ॥ **यावति विन्दजीवोः** ।३।४।३०। यावद्वेदं भुङ्क्ते । यावल्लभते तावदित्यर्थः । यावज्जीवमधीते ॥ **निमूलसमूलयोः कषः** ।३।४।३४। कर्मण्युपपदे ॥ **कषादिषु यथाविध्यनुप्रयोगः** ।३।४।४६। यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्यः । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः ॥ **शुष्कचूर्णरूक्षेषु पिषः** ।३।४।३५। एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् ॥ रूक्षपेषम् ॥ **समूलाकृतजीवेषु हन्कृञ्ग्रहः** ।३।४।३६। कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवन्तं गृह्णातीत्यर्थः ॥ **करणे हनः** ।३।४।३७। पादघातं हन्ति । पादेन हन्तीत्यर्थः ॥ **स्नेहने पिषः** ।३।४।३८। स्निह्यते येन तस्मिन्करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ **हस्ते वर्तिग्रहोः** ।३।४।३९। हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ **स्वे पुषः** ।३।४।४०। करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषेषु च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥ **समासत्तौ** ।३।४।५०। तृतीयासप्तम्योर्णमुल् सन्निकर्षे । केशग्राहं युध्यन्ते । हस्तग्राहं युध्यन्ते ॥ **स्वाङ्गे तस्प्रत्यये कृभ्वोः** ।३।४।६१। क्त्वाणमुलौ स्तः । मुखतः-

१ इह शाब्दबोधे विशेषसत्वेऽपि फलितार्थकथनपरतया कारमित्यस्य निष्फलत्वमुक्तमनतिप्रयोजनत्वात् । विस्तरस्तु मनोरमादावनुसंधेयः । २ असाकल्यमनेन दर्शयति । साकल्ये हि 'कर्मणि दृशिविदोः' इत्येव सिद्धम् । ३ निगतं मूलमस्य निमूलं । सह मूलेन समूलम् । निमूलसमूलकषणाभिन्नं कषणमिति शाब्दबोधः । ४ शुष्कचूर्ण इति सूत्रे एव स्नेहनग्रहणं न कृतम् । तत्र हि 'कर्मणि सृजिदृशोः' इति सूत्रात्कर्मणीत्यनुवर्तते । इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति । ५ केशेषु ग्रहणं भवतु मा वा संनिकर्षप्रतिपादनपरमेतत् ।

कृत्य । मुखतः कृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतोभावम्॥
॥ इति कृदन्तप्रक्रिया समाप्ता ॥

अथ विभक्त्यर्थाः ॥

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।२।३।४६। नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये सङ्ख्यामात्रे च प्रथमा । प्रातिपदिकार्थमात्रे—उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । लिङ्गमात्रे—तटः । तटी । तटम् । परिमाणमात्रे—द्रोणो व्रीहिः । वचनं सङ्ख्या । एकः । द्वौ । बहवः ॥ **संबोधने च** ।२।३।४७। प्रथमा । हे राम ॥ **कर्तुरीप्सिततमं कर्म** ।१।४।४९। कर्तुः क्रिययाप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ॥ **कर्मणि द्वितीया** ।२।३।२। अनुक्ते । हरिं भजति । अभिहिते तु कर्मादौ प्रथमैव । हरिः सेव्यते । लक्ष्म्या सेवितो हरिः । शतेन क्रीतः शत्यः अश्वः । प्राप्तानन्दश्चैत्रः । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । क्वचिन्निपातेनाभिधानम् । 'क्रमादमुं नारद इत्यबोधि सः' ॥ **अकथितं च** ।१।४।५१। अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् । "दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम्" । गां दोग्धि पयः । बलिं याचते वसुधाम् । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि

---

१ क्त्वाणमुलोः कृभुवोश्च यथासंख्यं नेष्यत इति भावः । २ यदाहि पञ्चकं प्रातिपदिकार्थ इति गृह्यते ततो लिङ्गवचनग्रहणमनर्थकं प्रातिपदिकार्थ इत्येव सिद्धेः । मात्रपदाच्च कर्मादिव्यवच्छेदो न स्यात् प्रातिपदिकार्थानतिरिक्तत्वात् । त्रिकपक्षेऽपि लिङ्गग्रहणमनर्थकमेवेत्याशङ्क्य विवक्षितं दर्शयति 'नियतोपस्थितिक' इति । यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स प्रातिपदिकार्थ इत्यर्थः । शक्य इति यावत् । ३ यद्यपि नीलद्रव्येऽयमनियतलिङ्गस्तथापि वासुदेवे भगवति नियतलिङ्ग इति भावः । ४ अपादानं संप्रदानमधिकरणं कर्म करणं कर्ता हेतुरित्येतैर्विशेषैरित्यर्थः । ५ मुख्यकर्मणा सह क्रियया संबध्यमानं कारकमेवापादानादिविशेषैरविवक्षितं सत् कर्मसंज्ञकं भवतीत्यर्थः । एतेन दुहादीनां द्विकर्मकत्वं स्फोरितम् ।

गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । (**अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्**) कुरून् स्वपिति । मासमास्ते । गोदोह[1]मास्ते । क्रोशमास्ते ॥ **गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ** ।१।४।५२। गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् । "शत्रू[2]नगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान् वेदमध्यापयद्विधिम् । आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः" ॥ (**नीव[3]ह्योर्न**) नाययति वाहयति वा भारं भृत्येन ॥ (**नियन्तृकर्तृकस्य वहेरनिषेधः**) । वाहयति रथं वाहान्सूतः ॥ (**आदिखाद्योर्न**) । आदयति खादयति वा अन्नं बटुना ॥ (**भक्षेरहिंसार्थस्य न**) । भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् । भक्षयति बलीवर्दान् सस्यम् ॥ (**जल्पतिप्रभृतीनामुपसङ्ख्यानम्**) । जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ॥ (**दृशेश्च**)। दर्शयति हरिं भक्तान् ॥ (**शब्दायतेर्न**) । शब्दाययति देवदत्तेन ॥ **हृक्रोरन्यतरस्याम्** ।१।४।५३। हृक्रोरणौ यः कर्ता स णौ वा कर्म स्यात् । हारयति कारयति भृत्येन भृत्यं वा कटम् ॥ (**अभिवादिदृशोरात्मनेपदे वेति वाच्यम्**)। अभिवादयते दर्शयते देवं भक्तेन भक्तं वा ॥ **अधिशीङ्स्थासां कर्म** ।१।४।४६। अधिपूर्वाणामेषामाधारः

---

१ न चेह कालत्वासिद्धिः । लोके कालत्वेन प्रसिद्धस्य मासादेरेव कालशब्देन ग्रहणात् । तेन घटमास्ते इत्यादि न भवति । जन्यमात्रं कालोपाधिरिति घटादेरपि कालत्वात् । २ शत्रवः स्वर्गमगच्छन् तान् श्रीहरिः स्वर्गमगमयत् । गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्माभवन् । स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः, एवमग्रेऽप्यूह्यम् । ३ यद्यप्येतयोः प्रापणमर्थो न गतिस्तथापि गतिरपि विशेषणीभूय प्रापणमध्ये प्रविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः ।

कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ **अभिनिविशश्च** ।१।४।४७। अभिनीत्येतत्संघातपूर्वस्य[1] विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । क्वचिन्न । पापेऽभिनिवेशः ॥ **उपान्वध्याङ्वसः** ।१।४।४८। उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः । अभुक्त्यर्थस्य तु न । वने उपवसति । 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते' । उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक्कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोधो लोकम् ॥ **(अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि)** अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । ऋते कृष्णम् । बुभुक्षितं न प्रतिभाति किंचित् ॥ **अन्तरान्तरेण युक्ते** ।२।३।४। द्वितीया । अन्तरा त्वां मां वा हरिः । अन्तरेण हरिं न सुखम् ॥ **कर्मप्रवचनीयाः**[2] ।१।४।८३। इत्यधिकृत्य ॥ **अनुर्लक्षणे** ।१।४।८४। लक्षणे द्योत्ये अनुः कर्मप्रवचनीयसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥ **कर्मप्रवचनीययुक्ते द्वितीया** ।२।३।८। जपमनुप्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः ॥ **तृतीयार्थे** ।१।४।८५। अनुरुक्तसंज्ञः । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ **हीने** ।१।४।८६। अनुरुक्तसंज्ञः । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥ **उपोऽधिके च** ।१।४।८७। अधिके हीने च उपेत्यव्ययं प्राग्वत् । अधिके सप्तमी वक्ष्यते । हीने । उप हरिं सुराः ॥ **लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः** ।१।४।९०। उक्तसंज्ञाः स्युः । लक्षणे । वृक्षं प्रति पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने । भक्तो विष्णुं प्रति पर्यनु वा । भागे । लक्ष्मीर्हरिं प्रति पर्यनु वा । हरेर्भाग इत्यर्थः ।

---

१ नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशसंघातविवक्षार्थमित्याह—संघातपूर्वस्येति । २ गुरुसंज्ञाकरणमन्वर्थताबोधनाय कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । बाहुलकाद्भूते कर्तर्यनीयर् । तेन संप्रति क्रिया न द्योतयन्तीति लभ्यते । तथाच हरिः—'क्रियाया द्योतको नायं संबन्धस्य न वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः' इति । ३ उत्कृष्टादेव द्वितीया शक्तिस्वभावात् ।

वीप्सायाम् । वृक्षं[1] वृक्षं प्रति पर्यनु वा सिञ्चति । एषु किम् । परिषिञ्चति ॥ **अभिरभागे** ।१।४।९१। भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभिवर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् । यदत्र ममाभिष्यात्तद्दीयताम् ॥ **सुः पूजायाम्** ।१।४।९४। सुसिक्तम् । । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् । सुषिक्तं किं तवात्र । क्षेपोऽयम् ॥ **अतिरतिक्रमणे च** ।१।४।९५। चात्पूजायामतिरुक्तसंज्ञः । अति देवान्कृष्णः ॥ **कालाध्वनोरत्यन्तसंयोगे**[2] ।२।३।५। इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः । स्वतन्त्रः कर्तेति कर्तृसंज्ञा ॥ **साधकतमं करणम्** ।१।४।४२। क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् ॥ **कर्तृकरणयोस्तृतीया** ।२।३।१८। अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥ **(प्रकृत्यादिभ्य उपसंख्यानम्)** । प्रकृत्या चारुः । प्रायेण[3] याज्ञिकः । गोत्रेण[4] गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून्गृह्णाति । सुखेन दुःखेन वा यातीत्यादि ॥ **दिवः कर्म च** ।१।४।४३। दिवः साधकतमं कर्मसंज्ञं स्याच्चात्करणसंज्ञं च । अक्षैरक्षान्वा दीव्यति ॥ **सहयुक्तेऽप्रधाने** ।२।३।१९। सहार्थेन युक्तेऽप्रधाने तृतीया । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूनेति निर्देशात् ॥ **येनाङ्गविकारः** ।२।३।२०। येनाङ्गेन विकृतेनाङ्गिनो[5] विकारो लक्ष्यते ततस्तृतीया । अक्ष्णा काणः । अक्षिसंबन्धिकाणत्वविशिष्ट इत्यर्थः ॥

---

१ इह वीप्सा द्विर्वचनेनैव द्योत्यते । प्रत्यादिशब्दस्तु क्रियया संबध्यते । कर्मण्येव द्वितीया । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाबाधात्षत्वं न । एतदर्थमेव लक्षणादयो विषयतयोपात्ता इति व्याख्यातमाकरे । २ अन्तं विराममतिक्रान्तोऽत्यन्तः स चासौ संयोगश्चात्यन्तसंयोगः निरन्तरसंनिकर्ष इत्यर्थः । केनेत्याकाङ्क्षायां गुणक्रियाद्रव्यैरिति औचित्याद्बोध्यम् । ३ एतद्गम्यमानक्रियां प्रति करणत्वात्सिद्धम् । आचारादिबाहुल्येन याज्ञिकोऽयमिति लोकैर्ज्ञायत इत्यर्थात् । ४ गार्ग्योऽस्य गोत्रमित्यर्थः । प्रथमात्र प्राप्ता । ५ सूत्रेऽङ्गशब्दोऽर्शआद्यजन्त इत्यर्थः ।

अपवर्गे तृतीया ।२।३।६। अपवर्गः फलप्राप्तिः तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वानुवाकोऽधीतः । अपवर्गे किम् । मासमधीतो नायातः ॥ **हेतौ** ।२।३।२३। तृतीया । दण्डेन घटः ॥ **इत्थंभूतलक्षणे** ।२।३।२०। तृतीया । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥ **संज्ञोऽन्यतरस्यां कर्मणि** ।२।३।२२। संपूर्वस्य जानातेः[1] कर्मणि तृतीया । पित्रा पितरं वा संजानीते ॥ **कर्मणा यमभिप्रैति स संप्रदानम्** ।१।४।३२। दानस्य कर्मणा यमभिप्रैति स संप्रदानसंज्ञः ॥ **चतुर्थी संप्रदाने** ।२।३।१३। अनुक्ते । विप्राय गां ददाति । क्रियया यमभिप्रैति सोऽपि संप्रदानम् । पत्ये शेते ॥ **परिक्रयणे संप्रदानमन्यतरस्याम्** ।१।४।४४। नियतकालं[2] भृत्या स्वीकरणं परिक्रयणं तस्मिन्साधकतमं कारकं संप्रदानं वा । शतेन शताय वा परिक्रीतः ॥ **(तादर्थ्ये चतुर्थी वाच्या)** मुक्तये हरिं भजति ॥ **(उत्पातेन[3] ज्ञापिते च)** । वातेन कपिला विद्युत् ॥ **नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च** ।२।३।१६। एभिर्योगे चतुर्थी स्यात् । हरये नमः । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि ॥ **ध्रुवमपायेऽपादानम्**[4] ।१।४।२४। अपायो विश्लेषस्तस्मिन् साध्ये ध्रुवमवधिभूतमपादानम् ॥ **अपादाने पञ्चमी** ।२।३।२८। ग्रामादायाति । धावतोऽश्वात्पतति इत्यादि ॥ **जनिकर्तुः प्रकृतिः** ।१।४।३०। जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥ **(ल्यब्लोपे कर्मण्यधिकरणे च)** । प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः ।

---

१ ज्ञा अवबोधने इत्ययमेव गृह्यते न तु जनी प्रादुर्भाव इति । तस्याकर्मकत्वात् । ङसः प्राग्भागस्य ज्ञ इत्यस्य 'अल्लोपोनः' इत्यनेन निष्पन्नत्वाल्लाक्षणिकत्वाच्चेत्याशयेनाह—जानातेरिति । २ द्रव्यदानेनात्यन्तस्वीकारः क्रयः, तस्य समीपं परिशब्द आचष्टे, अनियतकालात्क्रयणस्य न्यूनकालत्वादित्याशयेनाह—नियतेति । ३ प्राणिनां शुभाशुभसूचको भूतविकार उत्पातः तेन ज्ञापितेऽर्थे वर्तमानात् चतुर्थी वाच्येत्यर्थः । ४ प्रकृतधात्वर्थानाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमित्यर्थः ।

विभाषा गुणेऽस्त्रियाम् ।२।३।२५। गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियां किम् । बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥ **पृथग्विनानानाभिस्तृतीयान्यतरस्याम्** ।२।३।३६। एभिर्योगे तृतीया स्यात् पञ्चमीद्वितीये च । पृथग्ग्रामेण ग्रामाद् ग्रामं वा । एवं विना नाना ॥ **अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते** ।२।३।२९। अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम्[1] । अन्यो भिन्न इतरो वा कृष्णात् । आरात्[2] वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन संप्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् ॥ **अपपरी वर्जने** ।१।४।८८। एतौ वर्जनार्थे कर्मप्रवचनीयसंज्ञौ स्तः ॥ **आङ् मर्यादावचने** ।१।४।८९। आङ् मर्यादायामुक्तसंज्ञः । वचनग्रहणादभिविधावपि ॥ **पञ्चम्यपाङ्परिभिः** ।२।३।१०। एतैः कर्मप्रवचनीयैर्योगे पञ्चमी । अप हरेः परि हरेः संसारः । परिरत्र वर्जने । साहचर्यात् । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलाद्ब्रह्म ॥ **प्रतिः प्रतिनिधिप्रतिदानयोः** ।१।४।९२। एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥ **प्रतिनिधि[3]प्रतिदाने[4] च यस्मात्** ।२।३।२५। अत्र कर्मप्रवचनीययोगे पञ्चमी । प्रद्युम्नः कृष्णात् प्रति । तिलेभ्यः प्रति यच्छति माषान् ॥ **षष्ठी शेषे** ।२।३।५०। कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः शेषस्तत्र षष्ठी । राज्ञः[5] पुरुषः । कर्मादीनामपि संबन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥ **कर्तृ-**

---

१ नच 'इतरस्त्वन्यनीचयोः' इत्यमरोक्तनीचार्थस्येदं ग्रहणमिति वाच्यम्, अस्मात्तारो मन्द्रो वा इतिवत् 'पञ्चमी विभक्ते' इत्यनेनैव सिद्धत्वात् । २ इह दूरान्तिकार्थैरिति षष्ठी प्राप्ता । ३ मुख्यस्याभावे तत्सदृश एवोपादीयते स प्रतिनिधिः । ४ दत्तस्य प्रतिनिर्यातनं प्रतिदनाम् । ५ प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यादप्रधानादेव षष्ठी । प्रत्ययार्थस्त्विह पुरुषविशेषणम् ।

कर्मणोः कृति ।२।३।६५। कृद्योगे कर्तरि कर्मणि च षष्ठी। कृष्णस्य कृतिः[१]। जगतः[२] कर्ता कृष्णः। गुणकर्मणि वेष्यते। नेताश्वस्य स्रुघ्नं स्रुघ्नस्य वा। कृति किम्। तद्धिते मा भूत्। कृतपूर्वी कटम्॥ **उभयप्राप्तौ कर्मणि** ।२।३।६६। उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी। आश्चर्यो गवां दोहोऽगोपेन॥ **कृत्यानां कर्तरि वा** ।२।३।७१। षष्ठी। मया मम वा सेव्यो हरिः॥ **क्तस्य च वर्तमाने** ।२।३। ६७। वर्तमानार्थस्य क्तस्य योगे षष्ठी। नलोकेति वक्ष्यमाणनिषेधस्यापवादः। राज्ञां मतः बुद्धः पूजितो वा॥ **अधिकरणवाचिनश्च** ।२।३।६८। क्तस्य योगे षष्ठी। इदमेषां शयितम्॥ **न लोकाव्ययनिष्ठाखलर्थतृनाम्**[३] ।२।३।६९। एषां योगे षष्ठी न। लादेशः। कुर्वन् कुर्वाणः सृष्टिं हरिः। उः। हरिं दिदृक्षुः। अलंकरिष्णुर्वा। उक्। दैत्यान् घातुको हरिः। (**कमेरनिषेधः**)॥लक्ष्म्याः कामुकः। अव्ययम्। जगत्सृष्ट्वा। निष्ठा। दैत्यान् हतवान् विष्णुः। विष्णुना हता दैत्याः। खलर्थः। ईषत्करः प्रपञ्चो हरिणा। तृन्निति प्रत्याहारः। शतृशानचाविति तृशब्दादारभ्य तृनो नकारात्। शानच्। सोमं पवमानः। चानश्। आत्मानं मण्डयमानः। शतृ वेदमधीयन्। तृन् कर्ता लोकान्। (**द्विषः शतुर्वा**) मुरस्य मुरं वा द्विषन् (**सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः**) शेषे षष्ठी तु स्यादेव। ब्राह्मणस्य कुर्वन्। नरकस्य जिष्णुः। **अकेनोर्भविष्यदाधमर्ण्ययोः** ।२।३।७०। भविष्यत्यकस्य[४] भविष्यदाधमर्ण्यार्थेनश्च[५] योगे षष्ठी न। सतः पालकोऽवतरति। व्रजं गामी। शतं दायी। निमित्तपर्यायप्रयोगे सर्वासां विभक्तीनां प्रायदर्शनम्। किंनिमित्तं वसति। केन निमित्तेन। कस्मै निमित्तायेत्यादि। एवं किं कारणं को हेतुः किं प्रयोजनमित्यादि। प्राय-

---

१ करणं कृतिः स्त्रियां क्तिन् कृष्णोऽत्र कर्ता। २ कर्मण्युदाहरति—जगत इति। कृष्णस्य तृचाभिहितत्वात्ततः षष्ठी न भवति। ३ जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वं न कृतम्। उश्च उकश्च ऊकौ उश्चोकौ चेति विग्रहः। लइति लडादीनां सामान्यग्रहणं, तेषां च साक्षात्प्रयोगो न संभवतीति तदादेशा एव गृह्यन्ते। ४ आधमर्ण्ये अकस्यासंभवादाह—भविष्यत्यकस्येति। ५ इनस्तूभयोः संभवादाह—भविष्यदाधमर्ण्यार्थेनश्च योग इति। यथासंख्यं तु न भवति भाष्ये 'अकस्य भविष्यति' 'इन आधमर्ण्ये च' इति योगं विभज्य व्याख्यानात्।

ग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥ **षष्ठ्यतसर्थप्रत्ययेन** ।२।३।३०। ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥ **एनपा द्वितीया**।२।३।३१। एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥ **दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्** ।२।३।३४। एतैर्योगे षष्ठी पञ्चमी च । दूरं निकटं वा ग्रामस्य ग्रामाद्वा ॥ **दिवस्तदर्थस्य** ।२।३।५८। द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी । शतस्य दीव्यति । तदर्थस्य किम् । ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥ **विभाषोपसर्गे** ।२।३।५९। शतस्य शतं वा प्रदीव्यति ॥ **आधारोऽधिकरणम्** ।१।४।४५। कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञं स्यात् ॥ **सप्तम्यधिकरणे च** ।२।३।३६। चाद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा[2] । कटे[3] आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन् आत्मास्ति । वनस्य दूरेऽन्तिके वा । (**क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्**) । अधीती[4] व्याकरणे । (**साध्वसाधुप्रयोगे च**) साधुः कृष्णो मातरि । असाधुर्मातुले । **(निमित्तात्कर्मयोगे)** । 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः' ॥ **यस्य च भावेन भावलक्षणम्** ।२।३।३७ यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी । गोषु दुह्यमानासु गतः ॥ **षष्ठी चानादरे** ।२।३।३८। अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥ **स्वामीश्वराधिपतिदाया-**

---

१ आध्रियन्तेऽस्मिन्नित्याधारः । 'अध्यायन्याय' इति सूत्रे 'अवहाराधार–' इत्युपसंख्यानादधिकरणे घञ् । स च कस्येत्याकाङ्क्षायां कारकाधिकारात्क्रियाया इति लभ्यते । इयं च संज्ञा साक्षात्क्रियाधारयोर्न संभवति पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अतो व्याचष्टे–कर्तृकर्मद्वारेति । एवं च भूतले घट इत्यादौ, अस्तीति क्रियाध्याहारो बोध्यः ॥ २ नद्यामास्त इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति । ३ कर्मद्वारा क्रियाधारस्योदाहरणमिदम् । कर्तृद्वारा क्रियाधारस्य तु स्थाल्यां पचतीति । ४ भावे क्तप्रत्यये ततः 'इष्टादिभ्यश्च' इति कर्तरीनौ कृते पश्चाद्गुणभूतक्रियया संबध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वी कटमितिवद्द्वितीयात्र प्राप्ता ।

दसाक्षिप्रतिभूप्रसूतैश्च ।२।३।४०। एभिर्योगे षष्ठीसप्तम्यौ स्तः । गवां गोषु वा स्वामी ॥ **आयुक्तकुशलाभ्यां चासेवायाम्** ।२।३।३०। आभ्यां योगे षष्ठीसप्तम्यौ स्तः । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥ **यतश्च निर्धारणम्** ।२।३।४१। जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा गौर्बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥ **पञ्चमी विभक्ते** ।२।३।४२। विभागो विभक्तं । निर्धार्यमाणस्य यत्र भेद[1] एव तत्र पञ्चमी । माथुराः पाटलिपुत्रेभ्य आढ्यतराः ॥ **साधुनिपुणाभ्यामार्चायां सप्तम्यप्रतेः** ।२।३।४३। मातरि साधुर्निपुणो वा । आर्चायां किम् । निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ॥ **(अप्रत्यादिभिरिति वक्तव्यम्)** । साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥ **अधिरीश्वरे** ।१।४।८७। स्वस्वामिसंबन्धेऽधिः कर्मप्रवचनीयः ॥ **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी** ।२।३।९। अत्र कर्मप्रवचनीययुक्ते सप्तमी । उपपरार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वा[2]मिभ्यां पर्यायेण सप्तमी । अधिभुवि रामः । अधिरामे भूः ॥ इति विभक्त्यर्थाः ॥

अथ समासप्रकरणम् ।

समासः पञ्चधा । तत्र समसनं समासः । स च विशेषसंज्ञाविनिर्मुक्तः केवलसमासः प्रथमः । प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावो द्वितीयः । प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः । तत्पुरुषभेदः कर्मधारयः । कर्मधारयभेदो द्विगुः । प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः । प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः ॥ **[3]समर्थः प-**

---

१ न तु शब्दान्तरोपात्तसामान्याक्रान्ततेति भावः । २ अन्यतरस्मादुत्पन्नयैव सप्तम्या इतरनिष्ठसंबन्धस्याप्युक्तत्वाद्युगपदुभाभ्यां न सप्तमीति भावः । ३ सामर्थ्यं च द्विविधं व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति । तत्र स्वार्थे पर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परसंबन्धः सा व्यपेक्षा । सैव वाक्ये तत्र ह्यपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन संबन्धोऽभ्युपेयते । यथा राज्ञः पुरुषोऽश्वश्च । राज्ञो देवदत्तस्य च पुरुष इति । एकार्थीभावस्तु राजपुरुष इत्यादि वृत्तावेव, स च प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः ।

द्विधिः ।२।१।१। पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥ **प्राक्कडारात् समासः** ।२।१।३। कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥ **सह सुपा** ।२।१।४। सुप् सुपा सह वा समस्यते । समासत्वात्प्रातिपदिकत्वे सुपो लुक् । परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकोऽलौकिकश्च द्विधा । तत्र पूर्वं भूत इति लौकिकः । पूर्व अम् भूत सु इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः ॥ **(इवेन समासो विभक्त्यलोपश्च)**[1] । वागर्थौ इव वागर्थाविव । इति केवलसमासः ॥ **अव्ययीभावः** ।२।१।५। अधिकारोऽयम् । प्राक्तत्पुरुषात् ॥ **अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु** ।२।१।६। विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन नित्यं समस्यते । प्रायेणाविग्रहो नित्यसमासः । प्रायेणास्वपदविग्रहो वा । विभक्तौ हरि ङि अधि इति स्थिते ॥ **प्रथमानिर्दिष्टं समास उपसर्जनम्** ।१।२।४३। समासशास्त्रे[2] प्रथमानिर्दिष्टमुपसर्जनं स्यात् ॥ **उपसर्जनं पूर्वम्** ।२।२।३०। समासे उपसर्जनं प्राक् प्रयोज्यम् । इत्यधेः प्राक् प्रयोगः । सुपो लुक् । एकदेशविकृतस्यानन्यत्वात् प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः । अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक् । अधिहरि ॥ **अव्ययीभावश्च** ।१।४।१८। नपुंसकं स्यात् । गाः पातीति गोपाः तस्मिन्नित्यधिगोपम् ॥ **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** ।२।४।८३। अदन्तादव्ययीभावात्सुपो न लुक् तस्य पञ्चमीं विना अमादेशः कृष्णस्य समीपम् । उपकृष्णम् ॥ **तृतीयासप्तम्योर्बहुलम्** ।२।४।८४। अदन्तादव्ययीभावात् तृतीयासप्तम्योर्बहुलमम्भावः । उपकृष्णेन उपकृष्णम् । बहुलग्रहणात् । सुमद्रसुन्मत्तगङ्गमित्यादौ नित्यमम्भावः । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽति-

---

१ 'हरीतकीं भुङ्क्ष्व राजन् मातेव हितकारिणीम्' इत्यत्र मातेवेत्यशुद्धः पाठ इति बोध्यम् ।

२ अत्र समासपदं तद्विधायके लाक्षणिकम् । अन्यथा चिकीर्षिते समासे यत्प्रथमान्तमिति व्याख्यानप्रसक्त्या कृष्णं श्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इति ।

हिमम् । निद्रा संप्रति न युज्यतेऽतिनिद्रम् । हरिशब्दस्य प्रकाशः इतिहरि । विष्णोः पश्चादनुविष्णु । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । रूपस्य योग्यमनुरूपम् । अर्थमर्थं प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य यथाशक्ति ॥ **अव्ययीभावे चाकाले** ।६।३।८६। सहस्य सः स्यादव्ययीभावे न तु काले । हरेः सादृश्यं सहरि । काले तु सहपूर्वाह्णम् । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपत्सचक्रम्[1] । सदृशः सख्या ससखि । क्षत्राणां संपत्तिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणम् । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥ **यथाऽसादृश्ये** ।२।१।७। असादृश्ये एव यथाशब्दः समस्यते । नेह । यथा हरिस्तथाहरः ॥ **यावदवधारणे** ।२।१।८। यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा इति यावच्छ्लोकम् ॥ **सुप्प्रतिना मात्रार्थे** ।२।१।९। शाकस्य लेशः शाकप्रति[2] ॥ **विभाषा** ।२।१।११। अधिकारोऽयम् ॥ **अपपरिबहिरञ्चवः पञ्चम्या** ।२।१।१२। अप विष्णु संसारः । अप विष्णोः । परि विष्णु । परि विष्णोः । बहिर्वनम् । बहिर्वनात् । प्राग्वनम् । प्राग्वनात् ॥ **तिष्ठद्गुप्रभृतीनि च**[3] ।२।१।१७। एतानि निपात्यन्ते । तिष्ठन्ति गावो यस्मिन्काले स तिष्ठद्गुदोहनकालः ॥ **पारे मध्ये षष्ठ्या वा** ।२।२।१८। पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पारेगङ्गम् । गङ्गापारम् । मध्येगङ्गम् । गङ्गामध्यम् । महाविकल्पेन वाक्यमपि ॥ **संख्या वंश्येन** ।२।१।१९। वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः तद्वाचिना सह संख्या समस्यते ।

---

१ अत्र केचित् युगपच्चक्रमिति समासेनैव भाव्यं युगपच्छब्दस्याप्यव्ययत्वात् किं तु चक्रेणैककाले इत्यादि विग्रहीतुमुचितमित्याहुः । २ सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति—शाकप्रतीति । ३ तिष्ठद्गु, आयतीगवम्, खलेयवम्, खलेबुसम्, लूनयवम्, लूयमानयवम्, पूतयवम्, पूयमानयवम्, संहृतयवम्, संह्रियमाणयवम्, संहृतबुसम्, संह्रियमाणबुसम्, समभूमि, समपदाति, सुषमम्, विषमम्, दुःषमम्, निःषमम्, अपसमम्, आयतीसमम्, पापसमम्, पुण्यसमम्, प्राह्णम्, प्ररथम्, प्रमृगम्, प्रदक्षिणम्, संप्रति, असंप्रति, इच, इति तिष्ठद्ग्वादिः ।

द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि[1] । विद्यातद्वतामभेदविवक्षायां तु त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥ **नदीभिश्च** ।२।१।२०। नदीभिः संख्या वा समस्यते । समाहारे चायमिष्यते । पञ्चगङ्गम् । द्वियमुनम् ॥ **अन्यपदार्थे च संज्ञायाम्** ।२।१।२१। अन्यपदार्थे सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥ **तद्धिताः** ।४।१।७६। आपञ्चमसमाप्तेरधिकारोऽयम् ॥ **अव्ययीभावे शरत्प्रभृतिभ्यः** ।५।४।१०७। शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यत् । कियत् । जराया जरस् च । उपजरसम् ॥ **अनश्च** ।५।४।१०८। अन्नन्तादव्ययीभावाट्टच् ॥ **नस्तद्धिते** ।६।४।१४४। नान्तस्य भस्य टेर्लोपस्तद्धिते । उपराजम् । अध्यात्मम् ॥ **नपुंसकादन्यतरस्याम्** ।४।५।१०९। अन्नन्तं[2] यत् क्लीबं तदन्तादव्ययीभावाट्टच् वा स्यात् । उपचर्मम् । उपचर्म ॥ **झयः** ।५।४।११२। झयन्तादव्ययीभावाट्टच् वा स्यात् । उपसमित् । उपसमिधम् ॥ **नदीपौर्णमास्याग्रहायणीभ्यः** ।५।४।११०। वा[3] टच् स्यात् । उपनदम् । यस्येतिचेति इलोपः । उपनदीत्यादि ॥ **गिरेश्च सेनकस्य** ।५।४।११३। टच् वा स्यात् । उपगिरम् । उपगिरि ॥ **(प्रतिपरसमनुभ्योऽक्ष्णः)** । टच् स्यात् । अक्ष्णोऽभिमुखं प्रत्यक्षम् । अक्ष्णः परं परोक्षम् । अत एव समासः । परोक्षे लिडिति निपातनात्परस्यौकार इत्यादि ॥

इत्यव्ययीभावः ॥

---

१ पाणिनिकात्यायनपतञ्जलयस्त्रयो वंश्याः व्याकरणस्येति संबंधे षष्ठी । स्वपदाप्राधान्य एवायं समासः । यदा त्वन्यपदार्थप्राधान्यविवक्षा त्रयो वंश्या यस्येति तदा बहुव्रीहिरेव इत्याहुः । २ नपुंसकग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्याव्यभिचारादित्याह—अन्नन्तं यत्क्लीबमिति । ३ वृत्तिग्रन्थमनुरुध्येदं विकल्पकथनम् । परमार्थतस्तु नेहान्यतरस्यामनुवर्तते 'बहुगण' इति सूत्रस्थभाष्यविरोधात् ।

तत्पुरुषः ।२।१।२२। अधिकारोऽयं प्राग्बहुव्रीहेः ॥ **द्विगुश्च** ।२।१।२३। तत्पुरुषसंज्ञः ॥ **द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः** ।२।१।२४। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते । कृष्णं श्रितः । कृष्णश्रितः । इत्यादि ॥ **तृतीया तत्कृतार्थेन गुणवचनेन** ।२।१।३०। तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥ **पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः** ।२।१।३१। तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थः । माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुणमिश्रः । आचारश्लक्ष्णः ॥ **(अवरस्योपसंख्यानम्)** । मासावरः ॥ **अन्नेन व्यञ्जनम्** ।२।१।३४। संस्कारकद्रव्यवाचकं[1] तृतीयान्तमन्नेन सह प्राग्वत् । दध्ना उपसिक्तमोदनं दध्योदनम् ॥ **भक्ष्येण मिश्रीकरणम्** ।२।१।२५। गुडेन मिश्रा धाना गुडधानाः ॥ **कर्तृकरणे कृता बहुलम्** ।२।१।३२। कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखभिन्नः ॥ ❀ **कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्** ❀ ॥ नखनिर्भिन्नः ॥ **चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः** ।२।१।३६। चतुर्थ्यन्तार्थाय यत्तद्वाचिनार्थादिभिश्च चतुर्थ्यन्तं प्राग्वत् । यूपाय दारु यूपदारु । तदर्थेन प्रकृतिविकारभाव एवेष्टः । तेनेह न । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीतत्पुरुषाः ॥ **(अर्थेन नित्यसमासो[2] विशेष्यलिङ्गता चेति वक्तव्यम्)** । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥ **पञ्चमी भयेन[3]** ।२।१।३७। चोराद्भयं चोरभयम् ॥ **स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन** ।२।१।३९। **पञ्चम्याः स्तोकादिभ्यः** ।६।३।२। अलुगुत्तरपदे । स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः ।

---

१ व्याख्यानान्नेह स्वरूपग्रहणं तदाह—संस्कारकेत्यादि । २ अन्यथा विभाषाधिकारात्पक्षे द्विजायार्थ इति प्रयोगः स्यादिति भावः । ३ भयेति स्वरूपग्रहणं नार्थस्य प्रमाणाभावात् 'भयभीत' इति वार्तिकारम्भाच्च ।

दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः ॥ **षष्ठी** ।२।२।८। सुबन्तेन प्राग्वत् । राज्ञः पुरुषः राजपुरुषः ॥ **याजकादिभिश्च** ।२।२।९। षष्ठ्यन्तं समस्यते । वक्ष्यमाणस्यापवादः । ब्राह्मणयाजकः, देवपूजकः । याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, पत्तिगणक, इति याजकादिः ॥ **(गुणात्तरेण तरलोपश्च)** । तरबन्तं यद् गुणवाचि तेन समासः । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ॥ **न निर्धारणे** ।२।२।१०। षष्ठी न समस्यते । नृणां द्विजः श्रेष्ठः ॥ **पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन** ।२।२।११। पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे सतां षष्ठः[1] । गुणे काकस्य कार्ष्ण्यम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । सत् । द्विजस्य कुर्वन्कुर्वाणो वा । ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धम् । ब्राह्मणस्य कर्तव्यम् । तक्षकस्य सर्पस्य ॥ **क्तेन च पूजायाम्** ।२।२।१२। मतिबुद्धिसूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा ॥ **अधिकरणवाचिना[2] च** ।२।२।१३। क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥ **कर्मणि च** ।२।२।१४। उभयप्राप्तौ कर्मणीति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥ **तृजकाभ्यां कर्तरि** ।२।२।१५। कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः ॥ **कर्तरि च** ।२।२।१६। कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका ॥ **पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे** ।२।२।१। अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् ॥ **अर्धं नपुंसकम्** ।२।२।२। समांशवाच्यर्धशब्दो नित्यं क्लीबे स प्राग्वत् । अर्धं

---

१ षण्णां पूरणः षष्ठः । 'तस्य पूरणे डट्' 'षट्कतिकतिपयचतुरां थुक्' । कथं तर्हि 'तान्युञ्छषष्ठाङ्कितसैकतानि' इति । प्रमाद एवायमित्येके । उञ्छेषु षष्ठः उञ्छात्मकः षष्ठ इति वा व्याख्येयमिति मनोरमायाम् । २ वाचिग्रहणं चिन्त्यप्रयोजनमिति हरदत्तादयः ।

पिप्पल्या अर्धपिप्पली ॥ **(एकविभक्तावषष्ठ्यन्तवचनम्)** इत्युपसर्जनसंज्ञाबाधा-ह्रस्वो न । क्लीबे किम्। ग्रामार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥ **द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्** ।२।२।३। एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षायाः द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात्पूरणगुणेति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥ **प्राप्तापन्ने च द्वितीयया** ।२।२।४। पक्षे द्वितीयाश्रितेति समासः । प्राप्तो जीवनं प्राप्तजीवनः । जीवनप्राप्तः । आपन्नजीवनः । जीवनापन्नः । इह सूत्रे द्वितीयया अ इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ॥ **कालाः परिमाणिना** ।२।२।५। परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य यस्य स मासजातः ॥ **सप्तमी शौण्डैः** ।२।२।४०। सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्डः अक्षशौण्डः । शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर, अधिप, पटु, पण्डित, कुशल, चपल, निपुण इति शौण्डादिः ॥ द्वितीया तृतीयेत्यादियोगविभागादन्यत्रापि द्वितीयादीनां प्रयोगवशात्समासो ज्ञेयः ॥ **दिक्संख्ये संज्ञायाम्** ।२।१।५०। विशेषणं विशेष्येण बहुलमित्येव सिद्धे संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । तेनेह न । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥ **तद्धितार्थोत्तरपदसमाहारे च** ।२।२।५१। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत् । पूर्वस्यां शालायां भवः । पूर्वाशाला इति समासे जाते । सर्वनाम्नो वृत्तिमात्रे पूर्वं पुंवत् ॥ **दिक्पूर्वपदादसंज्ञायां ञः** ।४।२।१०७। अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम् ॥ **तद्धितेष्वचामादेः** ।७।२।१०७। ञिति णिति च तद्धिते अचामादेरचो वृद्धिः स्यात् । 'यस्येति च' पौर्वशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे

---

१ समासे अर्धपिप्पलीत्येव स्यात् । विशेष्यैक्यात् । परवल्लिङ्गातिदेशेऽपि वचनातिदेशाभावाच्चेति भावः । अर्धपिप्पल्य इति प्रयोगस्तु अर्धानि पिप्पलीनामिति विग्रहे असाधुश्चेदपि खण्डसमुच्चये साधुरेव । २ तत्पुरुषे संज्ञायामेव दिक्संख्ये समस्येते इति नियमशरीरम् ।

आकार उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् ॥ (**संख्यायास्तद्धितार्थे**) । षण्णां मातॄणामपत्यं षाण्मातुरः । 'मातुरुत्संख्यासंभद्रपूर्वायाः' इति वक्ष्यमाणोऽण् । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ अवान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ (**द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्**) ॥ **गोरतद्धितलुकि** ।५।४।९२। गोन्तात्तत्पुरुषाट्टच् स्यात्समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥ **संख्यापूर्वो द्विगुः** ।२।१।५२। तद्धितार्थेत्यत्रोक्तः संख्यापूर्वो द्विगुः ॥ **द्विगुरेकवचनम्** ।२।४।१। द्विग्वर्थः समाहार एकवत्स्यात् ॥ **स नपुंसकम्** ।२।४।१७। समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । पञ्चानां गवां समाहारः पञ्चगवम् ॥ **विशेषणं विशेष्येण बहुलम्** ।२।१।५७। भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥ (**अपरस्यार्धे पश्चभावो वक्तव्यः**) । अपरश्चासावर्धश्च पश्चार्धः ॥ **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** ।२।१।६१। सह समस्यन्ते । सद्वैद्यः ॥ **आन्महतः समानाधिकरणजातीययोः** ।६।३।४६। महावैयाकरणः ॥ **तत्पुरुषः समानाधिकरणः कर्मधारयः** ।१।२।४२। **पुंवत्कर्मधारयजातीयदेशीयेषु** ।६।३।४२। कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङ्भावो यस्मिन्तथाभूतं पूर्वं पुंवत् । पूरण्यां प्रियादिष्वप्राप्तः पुंवद्भावो विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥ **उपमानानि सामान्यवचनैः** ।२।१।५५। घनश्यामः ॥ **उपमितं व्याघ्रादिभिः सामान्याप्रयोगे** ।२।१।५६। **पुरुषो** व्याघ्र इव पुरुषव्याघ्रः । सामान्याप्रयोगे किम् । पुरुषो व्याघ्र इव शूरः ॥

---

१ वक्तीति वचनम् । बाहुलकात्कर्तरि ल्युट् । द्विगुः समास एकार्थप्रतिपादको भवतीत्यर्थः । २ विशेषणविशेष्ययोः ससंबन्धिकतया अन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोपादानं स्पष्टार्थमिति कैयटः । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनार्थं सूत्रम् । ४ व्याघ्र, सिंह, ऋक्ष, ऋषभ, चन्दन, वृक, वृष, वराह, हस्तिन्, तरु, पृषत्, पुण्डरीक, पलाश, कितव, इति व्याघ्रादिराकृतिगणः ॥ तेन घनश्यामः, नृसोमः, पार्थिवचन्द्र इत्यादि सिद्धम् ।

(शाकपार्थिवादीनामुत्तरपदलोपश्च) शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः ॥ **कडाराः कर्मधारये** ।२।२।३८। कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥ **मयूरव्यंसकादयश्च**[1] ।२।१।७२। एते निपात्यन्ते । मयूरो व्यंसको मयूरव्यंसकः । व्यंसको धूर्तः । उदक् च अवाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सोऽकिंचनः ॥ **(आख्यातमाख्यातेन क्रियासातत्ये)** । [2]अश्नीतपिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता । नास्ति कुतो भयं यस्य सः अकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥ **नञ्** ।२।२।६। सुपा प्राग्वत् ॥ **नलोपो नञः** ।६।३।७३। नञो नस्य लोप उत्तरपदे । अब्राह्मणः ॥ **तस्मान्नुडचि** ।२।३।७४। लुप्तनकारान्नञ उत्तरपदस्य[3]अजादेर्नुट् । अनश्वः । नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः ॥

---

१ मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड, यवनमुण्ड, । छन्दसि । हस्तेगृह्य, पादेगृह्य, लाङ्गूलेगृह्य, पुनर्दाय, (एहीडादयोऽन्यपदार्थे,) एहीडम्, एहिपचम्, एहिवणिजा क्रिया, अपेहिवणिजा, प्रेहिवणिजा, एहिस्वागता, अपेहिस्वागता, एहिद्वितीया, अपेहिद्वितीया, प्रेहिद्वितीया, एहिकटा, अपेहिकटा, प्रेहिकटा, अपहरकरटा, प्रोहिकरटा, प्रोहकर्दमा, प्रेहिकर्दमा, विधमचूडा, उद्धमचूडा, आहरचेला, आहरवनिता, आहरवसना, कृन्तविचक्षणा, उद्धरोत्सृजा, उद्धरावसृजा, उद्धमविधमा, उत्पतनिपचा, उत्पतनियता, उच्चावचम्, उच्चनीचम्, आचोपचम्, आचपराचम्, निश्चप्रचम्, अकिंचनः, स्नात्वाकालकः, पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्यपापीयान्, उत्पत्यपालका, निपत्यरोहिणी निषण्णश्यामा, अपेहिप्रघसा, एहिविघसा, इहपञ्चमी, इहद्वितीया, (जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति) जहिजोडः, जहिस्तम्बः, (आख्यातमाख्यातेन क्रियसातत्ये) अश्नीतपिबता, पचतभृज्जता, खादतमोदता, खादतवमता, आहरनिवपा, आहरविष्करा, भिन्धिलवणा, कृन्धिविचक्षणा, पचलवणा, पचप्रकूटा, आकृतिगणोयम् । तेन अकुतोभय, कान्दिशीक, आहोपुरुषिका, अहमहमिका, यदृच्छा एहिरेयाहिरा, उन्मृजविमृजा, द्रव्यान्तरम्, अवश्यकार्यम्, इत्यादि सिद्धम् । २ इह क्रियारूपस्यान्यपदार्थस्य प्राधान्यात्स्त्रीत्वाट्टाप् । एवमग्रेऽपि । ३ अचोत्तरपदविशेषणात् 'यस्मिन्विधिः—' इति तदादिविधिर्लभ्यत इति भावः ।

कुगतिप्रादयः ।२।२।१८। एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः ॥ **ऊर्यादिच्विडाचश्च**[1] ।१।४।६१। ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ (**कारिकाशब्दस्योपसंख्यानम्**) । कारिका क्रिया कारिकाकृत्य ॥ **अनुकरणं चानितिपरम्** ।५।४।६२। खाट्कृत्य । अनितिपरं किम् । खाडितिकृत्वा निरष्ठीवत् ॥ **आदरानादरयोः सदसती** ।१।४।६३। सत्कृत्य । असत्कृत्य ॥ **भूषणेऽलम्** ।१।४।६४। अलंकृत्य । भूषणे किम् । अलंकृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणमित्यादि त्रिसूत्री स्वभावात्कृञ्विषया ॥ **अन्तरपरिग्रहे** ।१।४।६५। अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥ **कणेमनसी श्रद्धाप्रतीघाते** ।१।४।६६। कणेहत्य[2] पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषाऽतिशये वर्तते । मनस्शब्दोऽप्यत्रैव ॥ **पुरोऽव्ययम्** ।१।४।६७। पुरस्कृत्य ॥ **अस्तं च** ।१।४।६८। अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥ **अच्छगत्यर्थवदेषु** ।१।४।६९। अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥ **अदोऽनुपदेशे** ।१।४।७०। अदःकृत्यादःकृतं[3] । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा । अदः कुरु ॥ **तिरोऽन्तर्द्धौ** ।१।४।७१। तिरोभूय ॥ **विभाषा कृञि** ।१।४।७२। **तिरसोऽन्यतरस्याम्** ।८।३।४२। सो वा स्यात्कुप्वोः । तिरःकृत्य । तिरस्कृत्य । तिरःकृत्वा ॥ **उपाजेन्वाजे** ।१।४।७३। एतौ कृञि वा गतिसंज्ञौ । उपाजेकृत्य । अन्वाजेकृत्य । उपाजे कृत्वा । अन्वाजे कृत्वा । दुर्बलस्य बल-

---

१ ऊरी, उररी, वेताली, धूसी, शकला, संसकला, ध्वंसकला, भ्रंसकला, गुलुगुधा, सजूः, फल, फली, विक्ली, आक्ली, आलोष्टी, केवाली, सेवाली, शेवाली, वर्षाली, मसमसा, मस्मसा, वौषट्, वषट्, श्रौषट्, स्वाहा, स्वधा, पाम्पी, प्रादुस्, श्रत्, आविस् । इत्यूर्यादिः ।

२ अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः । तथाच श्रद्धाया अपगमात्तत्प्रतीघातो गम्यते ।

३ यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् ।

माधायेत्यर्थः ॥ **साक्षात्प्रभृतीनि च** ।१।४।७४। कृञि वा गतिसंज्ञानि स्युः ॥ **(च्व्यर्थ इति वक्तव्यम्)**। साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥ **अनत्याधान उरसिमनसी** ।१।४।७५। उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषस्तत्र न । उरसि कृत्वा पाणिं शेते ॥ **मध्येपदे निवचने च** ।१।४।७६। एते कृञि गतिसंज्ञा वा स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥ **नित्यं हस्ते पाणावुपयमने** ।१।४।७७। कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये हस्तेकृत्य । पाणौकृत्य ॥ **प्राध्वं बन्धने** ।१।४।७८। प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनाकूलं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥ **जीविकोपनिषदावौपम्ये** ।१।४।७९। जीविकामिव कृत्वा । जीविकाकृत्य । औपम्ये । किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः ॥ **(प्रादयो गताद्यर्थे प्रथमया)** प्रगत आचार्यः प्राचार्यः ॥ **(अत्यादयः क्रान्ताद्यर्थे द्वितीयया)** अतिक्रान्तो मालामिति विग्रहे ॥ **एकविभक्तिचापूर्वनिपाते** ।१।२।४४। विग्रहे यन्नियतविभक्तिकं तदुपसर्जनं न तु तस्य पूर्वनिपातः ॥ **गोस्त्रियोरुपसर्जनस्य** ।१।२।४८। उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः । अतिमालः ॥ **(अवादयः क्रुष्टाद्यर्थे तृतीयया)** अवक्रुष्टः कोकिलयाऽवकोकिलः ॥ **(पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)** परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ **(निरादयः क्रान्ताद्यर्थे पञ्चम्या)** निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः ॥ **तत्रोपपदं सप्तमीस्थम्** ।३।१।९२। **उपपदमतिङ्** ।२।२।१९। उपपदं समर्थेन

१ साक्षात्, मिथ्या, चिन्ता, भद्रा, रोचना, आस्था, अमा, श्रद्धा, प्राजर्या, प्राजरुहा, बीजर्या, बीजरुहा, संसर्या, अर्थे, लवणम्, उष्णम्, शीतम्, उदकम्, आर्द्रम्, अग्नौ, वशे, विकसने, विहसने, प्रतपन, प्रादुस्, नमस्, आविस्, आकृतिगणोऽयम् । २ उरसिमनसी विभक्तिप्रतिरूपकौ । ३ सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ।

नित्यं समस्यते । अतिङश्चायं समासः । कुम्भं करोतीति कुम्भकारः । अतिङ् किम् । माभवान्भूत् । माङिलुङिति सप्तमीनिर्देशान्माङुपपदम् ॥ **गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः** । व्याघ्री । कच्छपी । अश्वक्रीतीत्यादि ॥ **अमैवाव्ययेन** ।२।२।२०। अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । 'स्वादुमि णमुल्' इति णमुल् । नेह । 'कालसमयवेलासु तुमुन्' । कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजं । अग्रे भुक्त्वा । विभाषाग्रे प्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥ **तृतीयाप्रभृतीन्यन्यतरस्याम्** ।२।२।२१। उपदंशस्तृतीयायामित्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् । उपदंशस्तृतीयायामिति णमुल् ॥ **क्त्वा च** ।२।२।२२। तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा ॥ **अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ** ।३।४।५९। **तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः** ।५।४।८६। संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम् । निरङ्गुलम् ॥ **अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः** ।५।४।८७। एभ्यो रात्रेरच् स्यात् । चात्संख्याव्ययादेः । अहर्ग्रहणं द्वन्द्वार्थम् ॥ **रात्राह्नाहाः पुंसि** ।२।४।२९। एते पुंस्येव । अहश्च रात्रिश्चाहोरात्रः[2] । सर्वरात्रः । पूर्वरात्रः । संख्यातरात्रः ॥ **(संख्यापूर्वं रात्रं क्लीबम्)** । द्विरात्रम् । अतिरात्रः ॥ **राजाहःसखिभ्यष्टच्** ।५।४।९१। एतदन्तात्तत्पुरुषाट्टच् । परमराजः । कृष्णसखः ॥ **अह्नष्टखोरेव** ।६।४।१४५। टिलोपः । उत्तमाहः ॥ **अह्नोऽह्न एतेभ्यः** ।५।४।८८। सर्वादिभ्योऽहन्शब्दस्याह्नादेशः समासान्ते परे ॥ **अह्नोऽदन्तात्** ।८।४।७। अदन्तपूर्वपदस्थान्निमित्तादह्नो नस्य णः । सर्वाह्णः ॥ **न संख्यादेः समाहारे** ।५।४।८९। अह्नोऽह्नादेशो न । द्व्यहः ॥ **उत्तमैकाभ्यां च** ।५।४।९०। अह्नोऽह्नादेशो न ।

---

१ असति ह्यव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत कुम्भकार इत्यत्र समासो न स्यात् । २ अह्नोरात्रिरिति षष्ठीतत्पुरुषस्यासंभवादिति भावः । ३ जातिरप्राणिनामित्येकवद्भावः ।

उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह ॥ (**पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा**) । पुण्याहम् । सुदिनाहम् । एकाहः ॥ **अग्राख्यायामुरसः** ।५।४।९३। टच् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ **ग्रामकौटाभ्यां च तक्ष्णः** ।५।४।९४। ग्रामतक्षः । कौटतक्षः ॥ **अतेः शुनः** ।५।४।९३। अतिश्वो वराहः ॥ **उपामानादप्राणिषु** ।५।४।९७। अप्राणिविषयोपमानवाचिनः शुनष्टच् । आकर्षः[1] श्वेव आकर्षश्वः ॥ **उत्तरमृगपूर्वाच्च सक्थ्नः** ।५।४।९८। चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥ **नावो द्विगोः** ।५।४।९९। द्विनावम् । त्रिनावम् ॥ **अर्धाच्च** ।५।४।१००। अर्धनावम् ॥ **खार्याः प्राचाम्** ।५।४।१०१। द्विगोरर्धाच्च खार्याष्टज्वा । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥ **द्वित्रिभ्यामञ्जलेः** ।५।४।१०२। द्व्यञ्जलम् । द्व्यञ्जलि ॥ **ब्रह्मणो जानपदाख्यायाम्** ।५।४।१०४। ब्रह्मान्तात्तत्पुरुषाट्टच् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥ **कुमहद्भ्यामन्यतरस्याम्** ।५।४।१०५। कुब्रह्मः[2] । कुब्रह्मा । महाब्रह्मः । महाब्रह्मा । 'प्रकारवचने जातीयर्' महाप्रकारो महाजातीयः ॥ **द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः** ।३।३।४७। आत्स्यात् । द्वादश । अष्टादश । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः ॥ (**प्राक्शताद्वक्तव्यम्**) । नेह । द्विशतम् ॥ **त्रेस्त्रयः**[3] ।६।३।४८। त्रिशब्दस्य त्रयसादेशः स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः ॥ **विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्** ।५।३।४९। द्व्यष्टनस्त्रेश्च प्रागुक्तं वा चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥ **परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः** ।२।४।२६। कुक्कुटमयूर्याविमौ । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ॥ **द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु न** । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः

१ उपमितं व्याघ्रादि—इति समासः । आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः काष्ठविशेषः । २ ब्राह्मणपर्यायो ब्रह्मन्शब्दः । ३ संधिवेलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेश इति ध्वनयन्नाह—त्रयस् इति ।

पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलंकुमारिः । अत एव ज्ञापकात् समासः । निष्कौशाम्बिः ॥ **पूर्ववदश्ववडवौ** ।२।४।२७। द्वित्वमतन्त्रम्[१] । अश्ववडवौ । अश्ववडवान् ॥ **अपथं नपुंसकम्** ।२।४।२९। तत्पुरुष इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तग्रहणान्नेह । अपन्थाः ॥ **(अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः)** पञ्चमूली ॥ **(आबन्तो वा)** । पञ्चखट्वम् । पञ्चखट्वी ॥ **(पात्राद्यन्तस्य न)** । पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ **छाया बाहुल्ये** ।२।४।२२। छायान्तस्तत्पुरुषो नपुंसकं स्यात् पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् ॥ **सभा राजामनुष्यपूर्वा** ।२।४।२३। राजपर्यायपूर्वोऽमनुष्यपूर्वश्च समासान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम्[२] । ईश्वरसभम् । अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् ॥ **विभाषा सेनासुराच्छायाशालानिशानाम्**[३] ।२।४।२५। एतदन्तस्तत्पुरुषः क्लीबं वा । ब्राह्मणसेनम् । ब्राह्मणसेना । इत्यादि ॥ **अशाला च** ।२।४।२४। संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । अशाला किम् । धर्मसभा । धर्मशालेत्यर्थः ॥ **अर्धर्चाः पुंसि च**[४] ।२।४।३१। अर्धर्चादयः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । एवं ध्वजतीर्थशरीरमण्डपयूषदेहाङ्कुशकलशसूत्रपात्रादयः सामान्ये नपुंसकम् । मृदु पचति । प्रातः कमनीयम् ॥ इति तत्पुरुषः ॥

---

१ द्वन्द्वग्रहणं तु नानुवर्तते अयोग्यत्वादिति भावः । २ इनशब्दोऽत्र राजपर्यायः । ईश्वरशब्दश्च । ३ प्रथमार्थे षष्ठीति सेनादिभिस्तत्पुरुषो विशेष्यते विशेषणेन तदन्तविधिरतदाह—एतदन्त इति । ४ अर्धर्च, गोमय, कषाय, कार्षापण, कुतप, कुणप, कपाट, शंख, गूथ, यूथ, ध्वज, कबन्ध, पद्म, गृह, सरक, कंस, दिवस, यूष, अन्धकार, दण्ड, कमण्डलु, मण्ड, भूत, द्वीप, द्यूत, चक्र, धर्म, कर्म, मोदक, शतमान, यान, नख, नखर, चरण, पुच्छ, दाडिम, हिम, रजत, सक्तु, पिधान, सार, पात्र, घृत, सैंधव, औषध, आढक, चषक, द्रोण, खलीन, पात्रीव, षष्टीक, वार, बाण, प्रोथ, कपित्थ, शुष्क, शाल, शील, शुल्क, शीधु, कवच, रेणु, ऋण, कपट, शीकर, मुसल, सुवर्ण, वर्ण, पूर्ण, चमस, क्षीर, कर्ष, आकाश, अष्टपद,

शेषो बहुव्रीहिः ।२।२।२३। अधिकारोऽयं प्राग्द्वन्द्वात् ॥ **अनेकमन्यपदार्थे** ।२।२।२४। अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः ॥ **सप्तमी विशेषणे बहुव्रीहौ** ।२।३।५। सप्तम्यन्तं विशेषणं बहुव्रीहौ पूर्वं स्यात् ॥ **हलदन्तात्सप्तम्याः संज्ञायाम्** ।६।३।९। हलन्तादद्न्ताच्च सप्तम्या अलुक् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । प्राप्तमुदकं यं स प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः ॥ **(प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः** प्रपतितपर्णः प्रपर्णः ॥ **(नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः)** अविद्यमानपुत्रोऽपुत्रः ॥ **स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु** ।६।३।३४। उक्तपुंस्काद्पर ऊङभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोरिति ह्रस्वः । चित्रगुः । रूपवद्भार्यः । अनूङः

मङ्गल, निधान, निर्यास, जम्भ, वृत्त, पुस्त, बुस्त, 'क्ष्वेडित' शृङ्ग, निगड, खल, मधु, मूल, मूलक, स्थूल, शेवाल, नाव, वप्र, विमान, मुख, प्रग्रीव, शूल, वज्र, कटक, कंटक, कर्पट, शिखर, कल्क, नाट, मस्तक, वलय, कुसुम, तृण, पङ्क, कुण्डल, किरीट, कुमुद, अर्बुद, अंकुश, तिमिर, आश्रम, भूषण, इल्कस, मुकुल, वसन्त, तडाग, पिटक, विडङ्क, पिण्याक, माष, कोश, फलक, दिन, दैवत, पिनाक, समर, स्थाणु, अनीक, उपवास, शाक, कर्पास, विशाल, चषाल, खण्ड, दर, विटप, रण, बल, मृणाल, हस्त, आर्द्र, हल, सूत्र, ताण्डव, गाण्डीव मण्डप, पटह, सौध, बोध, पार्श्व, शरीर, देह, फल, जल, पुर, राष्ट्र, बिम्ब, अम्बर, कुट्टिम, मण्डल, कुक्कुट, कुडप, ककुद, खण्डल, तोमर, तोरण, मञ्चक, पञ्चक, पुङ्ख बाल, छाल, वल्मीक, वर्ष, वस्त्र, वसु, उद्यान, उद्योग, स्नेह, स्तन, स्तेन, स्वर, संगम, निष्क, क्षेम, शूक, छत्र, क्षत्र, पवित्र, यौवन, कलह, पालक, वल्कल, कुञ्ज, विहार, लोहित, विषाण, भवन, अरण्य, पुलिन, हल, दृढ, आसन, ऐरावत, शूर्प, तीर्थ, लोमश, तमाल, लोह, दण्डक, त्रपथ, प्रतिसर, दारु, धनुस्, मान, वर्चस्क, कूर्च, तण्डक, मठ, सहस्र, ओदन, प्रवाल, शकट, अपराह्ण, नीड, शकल, तण्डुल, मुस्तक, इत्यर्धर्चादिः ॥ १ द्वितीयाश्रितेत्यादिना यस्य त्रिकस्य विशिष्यो समासो नोक्तः स शेषः । प्रथमान्तमित्यर्थः ।

किम् । वामोरूभार्यः । पूरण्यां तु ॥ **अप्पूरणीप्रमाण्योः** ।५।३।१५६। पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः । पुंवद्भावनिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव । रात्री पूरणीवाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥ **नद्यृतश्च** ।५।३।१५३। नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप् । पुंवद्भावः ॥ **केणः** ।७।३।१३। ह्रस्वः । इति प्राप्ते ॥ **न कपि** ।७।३।१४। ह्रस्वः । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । बाला । वामा । अबला । तनया । सामान्ये नपुंसकम् । दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥ **तसिलादिष्वाकृत्वसुचः** ।६।३।३५। तसिलादिषु कृत्वसुजन्तेषु स्त्रियाः पुंवत् । परिगणनं कर्तव्यम् । त्रतसौ । तरप्तमपौ । चरट्जातीयरौ । कल्पब्देशीयरौ । रूपप्पाशपौ । थाल् । तिल्थ्यनौ एषु परेषु स्त्रियाः पुंवत् । बह्वीषु इति बहुत्र । बहुत इत्यादि ॥ **(त्वतलोर्गुणवचनस्य)** शुक्लत्वम् । शुक्लता ॥ **(भस्याढे तद्धिते)** हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः ॥ **(कुक्कुट्यादीनामण्डादिषु)** कुक्कुटाण्डम् । मृगपदम् । मृगक्षीरम् । काकशावः ॥ **क्यङ्मानिनोश्च** ।६।३।३६। पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानिनी ॥ **न कोपधायाः** ।६।३।३७। स्त्रियाः पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी । कोपधप्रतिषेधे तद्धितवुग्ग्रहणम् । नेह । पाकभार्यः ॥ **संज्ञापूरण्योश्च** ।६।३।३८। न पुंवत् । दत्ताभार्यः । पञ्चमीभार्यः ॥ **वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे** ।६।३।३९। वृद्धिशब्देन विहिता या वृद्धिस्तद्धे-

---

१ तत्परत्वं स्पष्टार्थम् । २ 'पञ्चम्यास्तसिल्' इत्यारभ्य 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तेष्वित्यर्थः । ३ कुक्कुटी, मृगी, काकी, अण्ड, पद, शाव, भ्रकुंस, भ्रकुटी, इति कुक्कुट्यादिरण्डादिश्च ।

तुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्तात्स्त्री न पुंवत्। स्रौघ्नीभार्यः। रक्ते तु काषायकन्थः। विकारे तु हैममुद्रिकः॥ **स्वाङ्गाच्चेतः** ।६।३।४०। स्वाङ्गाद्य ईकारस्तदन्तात्स्त्री न पुंवत्। सुकेशीभार्यः। स्वाङ्गात्किम्। पटुभार्यः। ईतः किम्। अकेशभार्यः॥ **(अमानिनीति वक्तव्यम्)** सुकेशमानिनी॥ **जातेश्च** ।६।३।४१। न पुंवत्। ब्राह्मणीभार्यः। शूद्राभार्यः॥ **संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये** ।२।२।२५। संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः॥ **बहुव्रीहौ संख्येये डजबहुगणात्** ।५।४।७३। संख्येये यो बहुव्रीहिस्तस्माड्डच् समासान्तः। दशानां समीपे ये सन्ति ते उपदशाः। अबहुगणात् किम्। उपबहवः। उपगणाः॥ **तिविंशतेर्डिति** ।६।४।१४२। विंशतेर्भस्य तेर्लोपो डिति। आसन्नविंशाः। विंशतेरासन्ना इत्यर्थः। अदूरत्रिंशाः। अधिकचत्वारिंशाः। द्वौ वा त्रयो वा द्वित्राः॥ **दिङ्नामान्यन्तराले** ।२।२।२६। दिशो नामान्यन्तराले वाच्ये प्राग्वत्। दक्षिणस्याः पूर्वस्याश्च दिशो यदन्तरालं दक्षिणपूर्वा॥ **तत्र तेनेदमिति सरूपे** ।२।२।२७। सप्तम्यन्ते ग्रहणविषये[३] सरूपोपपदे तृतीयान्ते च प्रहरणविषये[४] इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे॥ **इच् कर्मव्यतिहारे** ।५।४।१२७। **अन्येषामपि दृश्यते** ।६।३।१३७। दीर्घः। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि। मुष्टीमुष्टि॥ **तेन सहेति तुल्ययोगे** ।२।२।२८। तुल्ययोगे वर्तमानं सहेत्यन्तं तृतीयान्तेन प्राग्वत्॥ **वोपसर्जनस्य** ।६।३।८२। बहुव्रीहेरवयवस्य सहस्य सः स्याद्वा। पुत्रेण सह सपुत्रः सहपुत्रो वागतः॥ **प्रकृत्याशिषि** ।६।३।८३। सहशब्दः। स्वस्ति राज्ञे सहपुत्राय सहामात्याय॥ **(अगोवत्सहलेष्विति वक्तव्यम्)**। सवत्साय। सहलाय॥ **बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्** ।५।४।११३। स्वाङ्गवाचि सक्थ्यन्ताद्बहुव्रीहेः षच्। दीर्घसक्थः। जलजाक्षी। स्वाङ्गात्किम्। दीर्घसक्थि शकटम्। स्थूलाक्षा

---

१ सामानाधिकरण्यस्यान्यपदार्थवृत्तेश्च विरहात्पूर्वेणाप्राप्तौ वचनम्। २ उपगता दश येषामिति न विगृहीतम्। पूर्वेणैव सिद्धेः। ३ गृह्यते इति ग्रहणं केशादिति तद्विषयो वाच्यो ययोस्तेषां सरूपे। ४ प्रह्रियन्तेऽनेनेति प्रहरणं दण्डादि तद्विषयो वाच्यो ययोरिति प्राग्वत्।

वेणुयष्टिः। अक्ष्णोदर्शनादिति वक्ष्यमाणोऽच्॥ **द्वित्रिभ्यां ष मूर्ध्नः**।५।४।११५। आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥ **अन्तर्बहिर्भ्यां च लोम्नः**।५।४।११७। अप् स्यात्। अन्तर्लोमः। बहिर्लोमः॥ **पादस्य लोपोऽहस्त्यादिभ्यः**।५।४।१३८। हस्त्यादिवर्जितादुपमानात्परस्य पादस्य लोपः। व्याघ्रस्येव पादौ यस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम्। हस्तिन इव पादौ यस्य हस्तिपादः। कुसूलपादः॥ **संख्यासुपूर्वस्य**। ५।४।१४०। पादशब्दस्य लोपः। द्विपात्। सुपात्॥ **उद्विभ्यां काकुदस्य**।५।४।१४८। लोपः। उत्काकुत्। विकाकुत्॥ **पूर्णाद्विभाषा**।५।४।१४९। पूर्णकाकुत्। पूर्णकाकुदः॥ **सुहृद्दुर्हृदौ मित्रामित्रयोः**।५।४।१५०। सुहृन्मित्रम्। दुर्हृदमित्रः॥ **(नेतुर्नक्षत्रे अब्वक्तव्यः)**। मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः॥ **अच् नासिकायाः संज्ञायां नसं चास्थूलात्**।५।४।११८। नासिकान्ताद्बहुव्रीहेरच् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात्॥ **पूर्वपदात्संज्ञायामगः**।८।४।३। पूर्वपदस्थान्निमित्तात्परस्य नस्य णो न तु गकारव्यवधाने। द्रुरिव नासिका यस्य द्रुणसः॥ **(खुरखराभ्यां वा नस्)**। खुरणाः। खरणाः। पक्षे अजपीष्यते। खुरणसः। खरणसः॥ **उपसर्गाच्च**।५।४।११९। उन्नसः॥ **(वेर्ग्रो वक्तव्यः)**। विगता नासिकाऽस्य विग्रः। **(ख्यश्च)** विख्यः॥ **नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्**।५।४।१२१। अहलः। अहलिः। असक्थः। असक्थिः। एवं दुःसुभ्याम्। शक्त्योरिति पाठान्तरम्। अशक्तः। अशक्तिः॥ **नित्यमसिच् प्रजामेधयोः**।५।४।१२२। नञ्दुःसुभ्य एव। अप्रजाः। अमेधाः। दुर्मेधाः। सुमेधाः॥ **धर्मादनिच् केवलात्**।५।४।१२४। केवलपूर्वपदाद्यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्। कल्याणधर्मा। केवलात् किम्। परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत्। परमस्वधर्मः॥ **(इच्कर्मव्यतिहारे)** केशाकेशि। मुसलामुसलि॥ **प्रसंभ्यां जानुनोर्ज्ञुः**।५।४।१२९। प्रज्ञुः।

---

१ हस्तिन्, कुद्दाल, अश्व, कशिक, कुरुत, कटोल, कटोलक, गण्डोल, गण्डोलक, कण्डोल, कण्डोलक, अज, कपोल, जाल, गण्ड, महेला, दासी, गणिका, कुसूल इति हस्त्यादिः।

संज्ञुः ॥ **ऊर्ध्वाद्विभाषा** ।५।४।१३०। ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥ **ऊधसो नङ्** ।५।४।१३१। कुण्डोध्नी ॥ **धनुषश्च** ।५।४।१३२। धनुरन्ताद्बहुव्रीहेरनङादेशः । शार्ङ्गधन्वा ॥ **वा संज्ञायाम्** ।५।४।१३३। शतधन्वा । शतधनुः ॥ **जायाया निङ्** ।५।४।१३४। जायान्तस्य बहुव्रीहेर्निङादेशः ॥ **लोपो व्योर्वलि** ।६।१।६६। युवतिर्जायाऽस्य युवजानिः ॥ **गन्धस्येदुत्पूतिसुसुरभिभ्यः** ।५।४।१३५। उद्गन्धिः । पूतिगन्धिः । सुगन्धिः ॥ **उपमानाच्च** ।५।४।१३७। पद्मस्येव गन्धोऽस्य पद्मगन्धिः । **वयसि दन्तस्य दतृ** ।५।४।१४३। संख्यासुपूर्वस्येत्येव । द्विदन् । चतुर्दन् ॥ **अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च** ।५।४।१४४। एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन्तः । कुड्मलाग्रदन् ॥ **उरःप्रभृतिभ्यः कप्** ।५।४।१५१। व्यूढोरस्कः । प्रियसर्पिष्कः ॥ (**अर्थान्नञः**) । अनर्थकम् । नञः किम् । अपार्थम् ॥ **इनः स्त्रियाम्** ।५।४।१४२। इन्नन्ताद्बहुव्रीहेः कप् । बहुदण्डिका नगरी ॥ (**अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति**) । बहुवाग्मिका ॥ **शेषाद्विभाषा** ।५।४।१५४। अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा । महायशाः । महायशस्कः । अनुक्तेत्यादि किम् । व्याघ्रपाद् ॥ **आपोऽन्यतरस्याम्** ।७।४।१५। कपि ह्रस्वः । बहुमालाकः । बहुमालकः । बहुमालः ॥ **न संज्ञायाम्** ।५।४।१५५। शेषादिति प्राप्तः कब् न । विश्वेदेवा अस्य विश्वेदेवः ॥ **ईयसश्च** ।५।४।१५६। ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोरिति ह्रस्वे प्राप्ते ॥ (**ईयसो बहुव्रीहेर्न**) । बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसी ॥ **वन्दिते भ्रातुः** ।५।३।१५७। पूजार्थभ्रात्रन्तान्न कप् । प्रशस्तो भ्राताऽस्य प्रशस्तभ्राता । सुभ्राता । वन्दिते किम् । मूर्खभ्रातृकः । नद्यृतश्चेति कप् ॥ (**सर्वनामसंख्येययोर्बहुव्रीहौ पूर्वनिपातः**) सर्वश्वेतः । द्विशुक्लः ॥ (**संख्याया अल्पीयस्याः**) द्वित्राः ॥ (**द्वन्द्वेऽपि**) द्वादश ॥ (**वा प्रियस्य**) गुडप्रियः । प्रियगुडः ॥ (**गड्वादेः परा सप्तमी**) गडुकण्ठः । क्वचिन्न । वहेगडुः ॥ **निष्ठा** २।२।३६।

---

१ उरस्, सर्पिस्, उपानह्, पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः, दधि, मधु, शालि, अर्थान्नञः । इत्युरःप्रभृतयः ।

सप्तमी विशेषणं बहुव्रीहौ
ह ... २।२।३५ ... २।२।३६

निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। कृतकृत्यः ॥ (**जातिकालसुखादिभ्यः परा निष्ठा वाच्या**[1])। सारङ्गजग्धी। मासजाता। सुखजाता ॥ **वाहिताग्न्यादिषु**। २।२।३७। आहिताग्निः। अग्न्याहितः। आकृतिगणोऽयम्[2]। इति बहुव्रीहिः ॥

चार्थे द्वन्द्वः।२।२।२९। अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः। तत्रेश्वरं गुरुं च भजस्वेति परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः। भिक्षामट गां चानयेति अन्यतरस्यानुषङ्गिकत्वेनान्वयोऽन्वाचयः। अनयोरसामर्थ्यात् समासो न। धवखदिरौ छिन्धीति मिलितानामन्वय इतरेतरयोगः। संज्ञापरिभाषमिति समूहः समाहारः ॥ **राजदन्तादिषु परम्**[3]।२।२।३१। एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजा राजदन्तः। धर्मादिष्वनियमः। अर्थधर्मौ। धर्मार्थौ। दम्पती। जम्पती। जायापती। जायाशब्दस्य दम्भावो जम्भावश्च वा निपात्यते। आकृतिगणोऽयम् ॥ **द्वन्द्वे घि**।२।२।३२। पूर्वं स्यात्। हरिहरौ ॥ **अजाद्यदन्तम्**।२।२।३३। ईशकृष्णौ ॥ **अल्पाच्तरम्**।२।२।३४। शिवकेशवौ ॥ (**ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण**।) हेमन्तशिशिरवसन्ताः। कृत्ति-

---

१ एतच्च 'जातिकालसुखादिभ्योऽनाच्छादनात्' इत्यनेन ज्ञापितमिति भावः। २ आहिताग्निः, जातपुत्रः, जातदन्तः, जातश्मश्रुः, तैलपीतः, घृतपीतः, ऊढभार्यः, गतार्थः, आकृतिगणोऽयम्। तेन गडुकण्ठ, अस्युद्यत, दण्डपाणि, इत्यादि ज्ञेयम्। इत्याहिताग्न्यादिः ॥ ३ राजदन्तः, अग्रेवणम्, लिप्तवासितम्, नग्नमुषितम्, सिक्तसंमृष्टम्, मृष्टलुञ्चितम्, अवक्लिन्नपक्वम्, अर्पितोप्तम्, उप्तगाढम्, उलूखलमुसलम्, तण्डुलकिण्वम्, दृषदुपलम्, आरग्वायनबन्धकी, चित्ररथबाह्लीकम्, अवन्त्यश्मकम्, शूद्रार्यम्, स्नातकराजानौ, विष्वक्सेनार्जुनौ, अक्षिभ्रुवम्, दारगवम्। धर्मादिषूभयम्। अर्थधर्मौ, धर्मार्थौ, अर्थशब्दौ, शब्दार्थौ, अर्थकामौ, कामार्थौ, वैकारिमतम्, गोजवाजम्, गोपालधानीपुलासम्, पुलासककरण्डम्, स्थूलपुलासम्, स्थलपुलासम्, उशीरबीजम्, सिञ्जास्थम्, चित्रास्वाती, भार्यापती, दम्पती, जम्पती, जायापती, पुत्रपती, पुत्रपशु, केशश्मश्रु, शिरोबीजम्, शिरोजानु, सर्पिर्मधुनी, मधुसर्पिषी, आद्यन्तौ, अन्तादी, गुणवृद्धी, वृद्धिगुणौ। आकृतिगणोऽयं राजदन्तादिः।

कारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ॥ (**लघ्वक्षरं पूर्वम्**) । कुशकाशम् । (**अभ्यर्हितं च**) तापसपर्वतौ ॥ (**वर्णानामानुपूर्व्येण**) । ब्राह्मणक्षत्रियविट्शूद्राः ॥ (**भ्रातुर्ज्यायसः**) । युधिष्ठिरार्जुनौ ॥ **द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्** ।२।४।२१। एषां द्वन्द्व एकवत् । पाणिपादम् ॥ मार्दङ्गिकवैणविकम् । रथिकाश्वारोहम् ॥ **अध्ययनतो विप्रकृष्टाख्यानाम्** ।२।४।५। अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥ **जातिरप्राणिनाम्** ।२।४।६। प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः ॥ **विशिष्टलिङ्गो नदीदेशोऽग्रामाः** ।२।४।४। ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां द्वन्द्व एकवत् । उध्यश्च इरावती च उध्येरावति । गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् ॥ **क्षुद्रजन्तवः**[1] ।२।४।८। एषां द्वन्द्व एकवत् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः ॥ **येषां च विरोधः शाश्वतिकः** ।२।४।८। प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वाद्विभाषा वृक्षेति प्राप्तं चकारेण बाध्यते ॥ **शूद्राणामनिरवसितानाम्** ।२।४।१०। अबहिष्कृतानां शूद्राणां द्वन्द्वः प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥ **गवाश्वप्रभृतीनि च** ।२।४।११। यथोच्चारितानि तथैव साधूनि । दासीदासमित्यादि ॥ **विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्** ।२।४।१२। वृक्षादीनां सप्तानां द्वन्द्वोऽश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः ।

---

१ क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसृतौ येषां केचिदानकुलावधि ।

२ गवाश्वम्, गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम्, कुब्जावामनम्, कुब्जकिरातम्, पुत्रपौत्रम्, श्वचाण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपटीकम्, शाटीप्रच्छदम्, शाटीपट्टिकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतीकम्, अर्जुनशिरीषम्, अर्जुनपुरुषम्, तृणोलपम्, दासीदासम्, कुटीकुटम्, भागवतीभागवतम्, एते गवाश्वप्रभृतयः ।

दधिघृतम्। दधिघृते। गोमहिषम्। गोमहिषाः। शुकबकम्। शुकबकाः। अश्ववडवम्। अश्ववडवौ। पूर्वापरम्। पूर्वापरे। अधरोत्तरम्। अधरोत्तरे॥ (**फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम्**)। बदराणि चामलकानि च बदरामलकम्। नेह। बदरामलके। रथिकाश्वारोहावित्यादि॥ **न दधिपयआदीनि**[1] ।२।४।१४। न एकवत्स्युः। दधिपयसी। इध्माबर्हिषी। निपातनाद्दीर्घः। ऋक्सामे। वाङ्मनसे॥ **आनङृतो द्वन्द्वे** ।६।३।२५। विद्यायोनिसंबन्धवाचिनां ऋदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे। होतापोतारौ। मातापितरौ। पुत्रे इत्यनुवृत्तेः पितापुत्रौ॥ **देवताद्वन्द्वे च** ।६।३।२६। इहोत्तरपदे पूर्वपदस्यानङ्। मित्रावरुणौ॥ (**वायोः प्रयोगे प्रतिषेधः**) अग्निवायू। वाय्वग्नी॥ **ईदग्नेः सोमवरुणयोः** ।६।३।२७। देवताद्वन्द्व इत्येव॥ **अग्नेः स्तुत्स्तोमसोमाः** ।८।३।८२। अग्नेः परेषामेषां सस्य षः समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमौ। अग्नीवरुणौ॥ **इद् वृद्धौ** ।६।३।२८। वृद्धिमत्युत्तरपदे अग्नेरिदादेशो देवताद्वन्द्वे। अग्नीमरुतौ देवते अस्य आग्निमारुतं कर्म। अग्नीवरुणौ देवते अस्य आग्निवारुणम्। देवताद्वन्द्वे चेत्युभयपदवृद्धिः॥ (**विष्णौ न**)। आग्नावैष्णवम्॥ **दिवो द्यावा** ।६।३।२९। देवताद्वन्द्वे उत्तरपदे। द्यावाभूमी॥ **मातरपितरावुदीचाम्** ।६।३।३२। उदीचां किम्। मातापितरौ॥ **द्वन्द्वाच्चुदषहान्तात्समाहारे** ।५।४।१०६। चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् समाहारे। वाक्त्वचम्। त्वक्स्रजम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारे किम्। प्रावृट्शरदौ। इति द्वन्द्वसमासः॥

अथैकशेषः॥ (**विरूपाणामपि समानार्थानाम्**)। वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ। कुटिलदण्डौ॥ **वृद्धो यूना तल्लक्षणश्चेदेव विशेषः** ।१।२।६५। यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं

---

१ दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिव्राजककौशिकौ, प्रवर्ग्योपसदौ, शुक्लकृष्णौ, इध्माबर्हिषी, दीक्षातपसी, अध्ययनतपसी, उलूखलमुसले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे, इति दधिपयआदयः।

वैरूप्यं स्यात्। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। वृद्धः किम्। गर्गगार्ग्यायणौ। यूना किम्। गर्गगार्ग्यौ। कृत्स्नं किम्। गार्ग्यवात्स्यायनौ॥ **स्त्रीपुंवच्च** ।१।२।६६। यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत्। गार्गी च गार्ग्यायणौ च गर्गाः॥ **पुमान्स्त्रिया** ।१।२।६७। स्त्रिया सहोक्तौ शिष्यते तल्लक्षण एव विशेषश्चेत्। हंसी च हंसश्च हंसौ॥ **भ्रातृपुत्रौ स्वसृदुहितृभ्याम्** ।१।२।६८। भ्राता च स्वसा च भ्रातरौ। पुत्रश्च दुहिता च पुत्रौ॥ **नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्** ।१।२।६९। अक्लीबेन सहोक्तौ क्लीबं[1] शिष्यते तच्च वा एकवत् स्यात्तल्लक्षण एव विशेषश्चेत्। शुक्लः पटः। शुक्ला शाटी। शुक्लं वस्त्रम्। तदिदं शुक्लम्। तानीमानि शुक्लानि॥ **पिता मात्रा** ।१।२।७०। मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ। मातापितरौ॥ **श्वशुरः श्वश्र्वा** ।१।२।७०। सहोक्तौ वा शिष्यते। श्वशुरौ। श्वश्रूश्वशुरौ॥ **त्यदादीनि सर्वैर्नित्यम्** ।१।२।७२। सर्वैः सहोक्तौ त्यदादीनि शिष्यन्ते। स च देवदत्तश्च तौ। (**त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते**) स च यश्च यौ। (**पूर्वशेषोऽपि दृश्यते**) इति भाष्यम्। स च यश्च तौ (**त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि**)। सा च देवदत्तश्च तौ। तच्च देवदत्ता च यज्ञदत्तश्च तानि॥ **ग्राम्यपशुसंघेष्वतरुणेषु स्त्री** ।१।२।७३। एषु सह विवक्षायां स्त्री शिष्यते। गाव इमाः। ग्राम्येति किम्। रुरव इमे। पशुग्रहणं किम्। ब्राह्मणाः। संघेषु किम्। एतौ गावौ। अतरुणेषु किम्। वत्सा इमे (**अनेकशफेष्विति वाच्यम्**) अश्वा इमे॥ **इत्येकशेषः**॥

ऋक्पूरब्धूः पथामानक्षे ।५।४।७५। ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः, अक्षे[2] या धूस्तदन्तस्य न। अर्धर्चः। अनृचबह्वृचावध्येतर्येव। नेह। अनृक् साम। बह्वृक् सूक्तम्। विष्णुपुरम्। विमलापं सरः॥ **द्व्यन्तरुपसर्गेभ्योऽप**

१ अन्यतरस्यांग्रहणं 'एकवच्च' इत्यनेनैवानन्तर्यात्संबध्यते नत्वेकशेषेणेत्याशयेनाह—क्लीबं शिष्यते तच्च वा एकवदिति। २ अनक्षे इत्येतत् सामान्यतः श्रुतमपि धुरैव संबध्यते सामर्थ्यात्, नान्यैरित्याशयेन व्याचष्टे—अक्षे या धूरिति।

ईत् ।६।३।९७। द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । अवर्णान्ताद्वा । प्रेपम् । प्रापम् ॥ **ऊदनोर्देशे** ।६।३।९८। अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथः । रम्यपथो देशः ॥ **अच्प्रत्यन्ववपूर्वात्सामलोम्नः** ।५।४।७५। प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अवलोमम् । (**कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते**) कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः । त्रिभूमः प्रासादः ॥ (**संख्याया नदीगोदावरीभ्यां च**)। पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥ **अक्ष्णोऽदर्शनात्** ।५।४।७६। अचक्षुःपर्यायादक्ष्णोऽच् स्यात् । गवामक्षीव गवाक्षः ॥ **अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः** ।५।४।७७। एते पञ्चविंशतिरजन्ता निपात्यन्ते[1] । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विगतानि चत्वार्यस्य विचतुरः । सुचतुरः ॥ (**त्र्युपाभ्यां चतुरोऽजिष्यते**) त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादश द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसी । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्तंदिवम् । रात्रौ च दिवा च रात्रिंदिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगू । द्व्यायुषं । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपं उपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥ **ब्रह्महस्तिभ्यां वर्चसः** ।५।४।७८। अच् । ब्रह्म-

---

१ निपातफलं तु समासविशेषनियमष्टिलोपादिकं च ।

वर्चसम् । हस्तिवर्चसम् ॥ (**पल्यराजभ्यां च**) । पल्यवर्चसम् । राजवर्चसम् ॥ **अवसमन्धेभ्यस्तमसः** ।५।४।७९। [1]अवतमसम् । संतमसम् । अन्धतमसम् ॥ **अन्ववतप्ताद्रहसः** ।५।४।८१। अनुरहसम् । अवरहसम् । तप्तरहसम् ॥ **प्रतेरुरसः सप्तमीस्थात्** ।५।४।८२। उरसीति प्रत्युरसम् ॥ **अनुगवमायामे** ५।४।८३। एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायाम इति समासः ॥ **उपसर्गाद्ध्वनः** ।५।४।८५। प्रगतोऽध्वानं प्राध्वो रथः ॥ **न पूजनात्** ।५।४।६९। पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । स्वतिभ्यामेव । नेह । परमराजः ॥ **किमः क्षेपे** ।५।४।७०। कुत्सितो राजा किंराजा । किंसखा । किंगौः ॥ **नञस्तत्पुरुषात्** ।५।४।७१। अराजा । तत्पुरुषात्किम् । अधुरं शकटम् ॥ **पथो विभाषा** ।५।४।७२। अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः ॥

इति समासान्ताः ॥

[2]**अलुगुत्तरपदे** ।६।३।१। इत्यधिकृत्य ॥ **ओजःसहोम्भस्तमसस्तृतीयायाः** ।६।३।२। ओजसा कृतमित्यादि ॥ (**अञ्जस उपसंख्यानम्**) । अञ्जसाकृतम् ॥ **आत्मनश्च** ।६।३।६। तृतीयाया अलुक् ॥ (**पूरणे इति वक्तव्यम्**) पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः ॥ **वैयाकरणाख्यायां चतुर्थ्याः** ।६।३।७। आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषा ॥ **परस्य च** ।६।३।८। परस्मैपदम् । परस्मैभाषा । हलदन्तादिति ङेरलुक् । त्वचिसारः ॥ **गवियुधिभ्यां स्थिरः** ।८।३।९५। सस्य षः । गविष्ठिरः । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायामिति सप्तमीसमासः ॥ (**हृद्द्युभ्यां च**) । हृदिस्पृक् । दिविस्पृक् ॥ **मध्याद्गुरौ** ।६।३।११। मध्येगुरुः । (**अन्ताच्च**) अन्तेगुरुः ॥ **अमूर्धमस्तकात्स्वाङ्गादकामे** ।६।३।१२। कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात्किम् । मूर्धशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥ **तत्पुरुषे**

१ अवहीनं संततं च तमः इति विग्रहः । २ प्रसज्यप्रतिषेधोयं 'सुपो धातु—'इत्यादिना प्राप्तो लुक् न भवतीत्यर्थः ।

कृति बहुलम् ।६।३।१४। स्तम्बेरमः । कर्णेजपः ॥ **शयवासवासिष्वकालात्** ।६।३।१८। वा लुक् । खेशयः । खशयः । ग्रामेवासः ग्रामवासः । ग्रामेवासी ग्रामवासी ॥ **षष्ठ्या आक्रोशे** ।६।३।२१। चोरस्य कुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ॥ **(वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु)** । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ **(आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च) (देवानांप्रिय इति च मूर्खे)**[1] अन्यत्र देवप्रियः ॥ **(शेपपुच्छलाङ्गूलेषु शुनः)** शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः ॥ **(दिवश्च दासे)** दिवोदासः॥ **ऋतो विद्यायोनिसंबन्धेभ्यः** ।६।३।२३। होतुरन्तेवासी ॥ **विभाषा स्वसृपत्योः** ।६।३।२४। ऋदन्तात्षष्ठ्या वा लुक् ॥ **मातुः पितुर्भ्यामन्यतरस्याम्** ।८।३।८५। स्वसुः सस्य षः समासे । मातुःष्वसा । मातुःस्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥ **मातृपितृभ्यां स्वसा** ।८।३।८४। स्वसुः सस्य षः समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा । इत्यलुक्समासः ॥

घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ।६।३।४३। भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् । घरूपकल्पप्रत्यये चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा[2] । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रेत्यादि । ब्रुवः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥ **नद्याः शेषस्यान्यतरस्याम्** ।६।३।४०। अङ्यन्तनद्या ङ्यन्तैकाचश्च घादिषु ह्रस्वो वा । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ **(कृन्नद्या न)** लक्ष्मीतरा ॥ **उगितश्च** ।६।३।४५। उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा[3] । ह्रस्वाभावपक्षे पुंवत् । विद्वत्तरा ॥ **पादस्य प-**

---

१ ब्रह्मज्ञानरहितत्वात्संसारिणो मूर्खास्ते तु यागादिकर्माण्यनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानामत्यन्तं प्रीतिं जनयन्ति । २ 'जातेश्च' इति निषेधात्तसिलादिष्विति न पुंवद्भावः । ३ उगितश्चेति ङीपि वसोः संप्रसारणम् ।

दाज्यातिगोपहतेषु ।६।३।५२। एषूत्तरपदेषु पादस्य पद इत्यदन्तादेशः स्यात् । पादाभ्यां अजतीति पदाजिः । पदातिः ॥ **'अज्यतिभ्यां पादे च'** इतीण् प्रत्ययः । पदगः । पदोपहतः ॥ **पद्यत्यतदर्थे** ।६।३।५३। पादस्य पत्स्यादतदर्थे यति । पादौ विध्यन्ति पद्याः शर्कराः । विध्यत्यधनुषेति यत् । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यामिति यत् ॥ **उदकस्योदः संज्ञायाम्** ।६।३।५७। उत्तरपदे । उदमेघः ॥ **(उत्तरपदस्य चेति वक्तव्यम्)** क्षीरोदः ॥ **पेषंवासवाहनधिषु च** ।६।३।५८। उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः ॥ **एकहलादौ पूरयितव्येऽन्यतरस्याम्** ।६।३।५९। उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः । **मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च** ।६।३।६०। उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥ **इको ह्रस्वोऽङ्यो गालवस्य** ।६।३।६३। इगन्तस्याङ्यन्तस्य ह्रस्वो वा उत्तरपदे । ग्रामणिपुत्रः । ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः किम् । गौरीपतिः ॥ **ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे** ।६।१।१३। ष्यङन्तस्य पूर्वपदस्य संप्रसारणं स्यात् पुत्रपत्योः परतः ॥ **संप्रसारणस्य** ।६।३।१३९। दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः ॥ **इष्टकेषीकामालानां चिततूलभारिषु** ।६।३।६५। इष्टकादीनां तदन्तानां च चितादिषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम्[1] । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥ **ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु** ।६।३।८५। समानस्य सः । सज्योतिः ॥ **चरणे ब्रह्मचारिणि** ।६।३।८६। ब्रह्मचारिण्युत्तरपदे समानस्य सश्चरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः । तदध्ययनार्थं व्रतमपि ब्रह्म । तच्चरतीति ब्रह्मचारी । सब्रह्मचारी इत्यादि ॥ **तीर्थे ये[2]** ।६।३।८७। यादौ प्रत्यये विवक्षिते समानस्य सः । सतीर्थ्यः एकगुरुकः । समान-

---

१ पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः । २ येइत्यत्र अकारो न विवक्षितः । प्रत्यय इति विशेष्यं तु व्याख्यानाल्लभ्यते ।

तीर्थेवासीति यत्प्रत्ययः ॥ **विभाषोदरे** ।६।३।८८। सोदर्यः । समानोदर्यः ॥ **दृग्दृशवतुषु** ।६।३।८९। सदृक् । सदृशः ॥ **(दृक्षे च)** । सदृक्षः ॥ **इदंकिमोरीश्की** ।६।३।९०। दृग्दृशवतुषु । ईदृक् । ईदृशः । कीदृक् । कीदृशः ॥ **(दृक्षे च)** । ईदृक्षः । कीदृक्षः ॥ **अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु** ।६।३।९९। अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । [1]अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अषष्ठीत्यादि किम् । अन्यस्यान्येन वाशीः अन्याशीः ॥ **(कारके छे च [2]नायं निषेधः)** । अन्यस्य कारकोऽन्यत्कारकः । अन्यस्यायमन्यदीयः ॥ **अर्थे विभाषा** ।६।३।१००। अन्यदर्थः । अन्यार्थः ॥ **कोः कत्तत्पुरुषेऽचि** ।६।३।१०१। अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ **(त्रौ च)** कत्त्रयः ॥ **रथवदयोश्च** ।६।३।१०२। कद्रथः । कद्वदः । **तृणे च जातौ** ।६।३।१०३। कत्तृणम् ॥ **का पथ्यक्षयोः** ।६।३।१०४। कापथम् । काक्षः ॥ **ईषदर्थे** ।६।३।१०५। ईषज्जलं काजलम् ॥ **विभाषा पुरुषे** ।६।३।१०६। कुपुरुषः । कापुरुषः ॥ **कवं चोष्णे** ।६।३।१०७। उष्णशब्दे उत्तरपदे कवं का च वा स्यात् । कोष्णम् । कवोष्णम् । कदुष्णम् ॥ [3]**पृषोदरादीनि यथोपदिष्टम्** ।६।३।१०९। पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि । पृषत उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य वः उत्तरपदादेश्च लत्वम् । 'भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥' **मतौ बह्वचोऽनजिरादीनाम्** [4] ।६।३।११९। दीर्घः स्यात् । अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥ [5]**शरादीनां च**

---

१ अन्यदाशीः इत्यादयः कर्मधारयाः । २ एतच्च 'अषष्ठीतृतीयास्थ—' इत्येव सिद्धे निषेधानित्यत्वज्ञापनार्थाद्विर्नञ उपादानाल्लभ्यते । ३ पृषोदर, पृषोत्थान, बलाहक, जीमूत, स्मशान, उलूखल, पिशाच, बृसी, मयूर, इति पृषोदरादिः । ४ अजिर, खदिर, पुलिन, हंस, कारण्डव, चक्रवाक, इत्यजिरादिः । ५ शर, वंश, धूम, अहि, कपि, मणि, मुनि, शुचि, हनु, इति शरादिः ।

६।३।१२०। शरावती ॥ **उपसर्गस्य घञ्यमनुष्ये बहुलम्**। ६।३।१२२। परीपाकः। परिपाकः। अमनुष्ये किम्। निषादः ॥ **नरे संज्ञायाम्**।६।३।१२९। विश्वानरः ॥ **मित्रे चर्षौ**।६।३।१३०। विश्वामित्रः। (**शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु**)। श्वादन्तः ॥ **प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि**।८।४।२। एभ्यः परस्य वनस्य नस्य णत्वम्। प्रवणम् ॥ **विभाषौषधिवनस्पतिभ्यः**।८।४।६। दूर्वावणम्।दूर्वावनम्। शिरीषवणम्। शिरीषवनम् ॥ (**द्व्यच्त्र्यज्भ्यामेव**)। नेह। देवदारुवनम् ॥ (**इरिकादिभ्यो न**) इरिकावनम्[1]। मिरिकावनम् ॥ **वाहनमाहितात्**।८।४।८। आरोप्य यदुह्यते तद्वाचिस्थान्निमित्ताद्वाहनस्य नस्य णत्वम्। इक्षुवाहणम्। आहितात्किम्। इन्द्रवाहनम् ॥ **पानं देशे**।८।४।९६। पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णः। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। सुरापाणाः प्राच्याः ॥ **वा भावकरणयोः**।८।४।१०। क्षीरपानम्। क्षीरपाणम् ॥ **प्रातिपदिकान्तनुम्विभक्तिषु च**।८।४।११। पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा। माषवापिणौ। व्रीहिवापेण। माषवापेण। पक्षे माषवापिनावित्यादि ॥ **कुमति च**।८।४।१३। कवर्गवत्युत्तरपदे प्राग्वत्। हरिकामिणौ। हरिकामाणि। हरिकामेण ॥ **पदव्यवायेऽपि**।८।४।३८। णत्वं न। माषकुम्भवापेन। (**अतद्धित इति वक्तव्यम्**)। आर्द्रगोमयेण। शुष्कगोमयेण ॥ **पारस्करप्रभृतीनि च संज्ञायाम्**।६।१।१५७। एतानि ससुट्कानि निपात्यन्ते। पारस्करः। किष्किन्धा ॥ (**तद्बृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च**)। तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः। तद्बृहतोर्दकारतकारौ लुप्येते करपत्योस्तु सुट्। चौरदेवतयोरिति समुदायोपाधिः। तस्करः। बृहस्पतिः ॥ (**प्रायस्य चित्तिचित्तयोः**) प्रायश्चित्तिः। प्रायश्चित्तम्। वनस्पतिरित्यादि। आकृतिगणोऽयम्।

इति समासाश्रयविधयः।

---

१ इरिका, मिरिका, तिमिरा, इतीरिकादिराकृतिगणः।

अथ तद्धितप्रकरणम् ।

समर्थानां प्रथमाद्वा ।४।१।८२। इदं पदत्रयमधिक्रियते[1] प्राग्दिश इति यावत् ॥ **प्राग्दीव्यतोऽण्** ।४।१।८३। तेन दीव्यतीत्यतःप्रागणधिक्रियते ॥ **अश्वपत्यादिभ्यश्च**[2] ।४।१।८४। एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु । अश्वपतेरपत्याद्याश्वपतम् । गाणपतम् ॥ **दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः** ।४।१।८५। प्राग्दीव्यतीयेष्वर्थेषु । दितेरपत्यादि दैत्यः । अदितेरादित्यस्य वा आदित्यः ॥ (**यणो मयो द्वे वाच्ये**) मय इति पञ्चमी यण इति षष्ठीति पक्षे यस्य द्वित्वम् ॥ **हलो यमां यमि लोपः** ।८।४।३४। वा स्यात् । इत्यसति लोपे द्वित्वे च सति त्रियं रूपम् । असति लोपे द्वित्वलोपयोर्वा द्वियम् । द्वित्वाभावे लोपे च सति एकयम् । प्राजापत्यः (**देवाद्यञञौ**) दैव्यम् । दैवम् ॥ (**बहिषष्टिलोपो यञ्च**) । बाह्यः ॥ (**ईकक् च**) ॥ **किति च** ।७।२।११८। किति तद्धितेऽचामादेरचो वृद्धिः । बाहीकः (**गोरजादिप्रसङ्गे यत्**) गोरपत्यादि गव्यम् ॥ **उत्सादिभ्योऽञ्**[3] ।४।१।८६। औत्सः । इत्यपत्यादिविकारान्तार्थाः प्रत्ययाः ॥

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ।४।१।८७। धान्यानां भवन इत्यतः प्रागर्थेष्वाभ्यामेतौ स्तः । स्त्रैणः । पौंस्नः ॥ **तस्यापत्यम्** ।४।१।९२। षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥ **ओर्गुणः** ।६।४।१४६।

---

१ अनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता । तत्प्रयोजनं तु कस्यचिन्निवृत्तावपि अपरस्यानिवृत्तिः । तथा च 'प्राग्दिशः–' इति सूत्रे 'समर्थानां प्रथमात्' इति निवृत्तं 'वा' इति त्वनुवर्तत एव इति वक्ष्यमाणमूलग्रन्थः संगच्छते । २ अश्वपति, स्थानपति, ज्ञानपति, यज्ञपति, बन्धुपति, शतपति, धनपति, गणपति, राष्ट्रपति, कुलपति, गृहपति, पशुपति, धान्यपति, धर्मपति, धन्वपति, सभापति, प्राणपति, क्षेत्रपति, इत्यश्वपत्यादिः । ३ उत्स, उदपान, विकिर, विनद, महानद, महासन, महाप्राण, तरुण, तलुन, बष्कयास, धेनु, पृथ्वी, पङ्क्ति, जगती, त्रिष्टुप्, अनुष्टुप्, जनपद, भरत, उशीनर, ग्रीष्म, पीलु, कुण, उदस्थान, देशे, पृषदंश, भल्लकीय, रथन्तर, मध्यन्दिन, बृहत्, महत्, सत्वत्, कुरु, पञ्चाल, इन्द्रावसान, उष्णिह, ककुभ्, सुवर्ण, देव, ग्रीष्माच्छन्दसि, इत्युत्सादिः ।

उवर्णान्तस्य भस्य गुणस्तद्धिते। ओरोदिति वक्तव्ये गुणोक्तिः संज्ञापूर्वको विधिरनित्य इति ज्ञापयितुम्। तेन स्वायंभुवमित्यादि सिद्धम्। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पौंस्नः॥ **अपत्यं पौत्रप्रभृति गोत्रम्। ४।१।१६२।** अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥ **एको गोत्रे ४।१।९३।** गोत्रे एक एव प्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥ **गर्गादिभ्यो यञ् ।४।१।१०५।** गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥ **यञञोश्च ।२।४।६४।** गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥ **गोत्रेऽलुगचि ।४।१।८९।** अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक् स्यात्। गर्गाणां छात्राः। वक्ष्यमाणो वृद्धाच्छः॥ **आपत्यस्य च तद्धितेऽनाति ।६।१।५१।** हलः परस्यापत्यस्य लोपस्तद्धिते नत्वाकारे। गार्गीयाः। अनाति किम्। गार्ग्यायणः। प्राग्दीव्यतीये किम्। गर्गेभ्यो हितं गर्गीयम्। अचि किम्। गर्गेभ्यः आगतं गर्गरूप्यम्॥ **जीवति तु वंश्ये युवा ।४।१।१६३।** वंश्यो पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यान्न तु गोत्रसंज्ञम्॥ **गोत्राद्यून्यस्त्रियाम् ।४।१।९५।** यून्यपत्ये विवक्षिते गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्स्त्रियां तु न युवसंज्ञा॥ **यञिञोश्च। ।४।१।१०१।** गोत्रे यौ यञिञौ तदन्तात्फक्॥ **आयनेयीनीयियः फढखछघां**

---

१ गर्ग, वत्स, वातासे, संस्कृति, अज, व्याघ्रपात्, विदभृत्, प्राचीनयोग, अगस्ति, पुलस्ति, चमस, रेभ, अग्निवेश्य, शंख, शठ, शक, एक, धूम, अवट्, मनस्, धनंजय, वृक्ष, विश्वावसु जरमाण, लोहित, सशित, बभ्रु, वल्गु, मण्डु, गण्डु, शकु, लिंगु, गुहुलु, मनु, मङ्क्षु, आलिगु, मतु, जिगीषु, मनु, तन्तु, मनायी, सूनु, कथक, कत्थक, ऋक्ष, तृक्ष, तनु, तरुक्ष, तलुक्ष, तण्ड, वतण्ड, कपि, कत, कुरुकत, अनडुह्, कण्व, शकल, गोकक्ष, अगस्त्य, कुण्डिनी, यज्ञवल्क, पर्णवल्क, अभयजात, विरोहित, वृषगण, रहूगण, शण्डिल, चणक, चुलुक, मुद्गल, मुसल, जमदग्नि, पराशर, जतुकर्ण, महित, मन्त्रित, अश्मरथ, शर्कराक्ष, पूतिमोष, स्थूर, अररका, एरका, पिङ्गल, कृष्ण, गोलन्द, उलूक, तितिक्ष, भिषज्, भिष्णज्, भडित, भण्डित, दल्भ, चैकित, चिकित्सित, देवहू, इन्द्रहू, एकलू, पिप्पलू, बृहदग्नि, सुलाभिन्, उक्थ, कुटीगु, इति गर्गादिः॥

प्रत्ययादीनाम् ।७।१।२। प्रत्ययादेः फस्य आयन् ढस्य एय् खस्य ईन छस्य ईय घस्य इय् स्युः । गर्गस्य युवापत्यं गार्ग्यायणः ॥ **अत इञ्** । ४।१।९५। अपत्येऽर्थे । दाक्षिः ॥ **बाह्वादिभ्यश्च**[1] ।४।१।९६। बाहविः । औडुलोमिः । औडुलोमी ॥ **(लोम्नोपत्येषु बहुष्वकारो वक्तव्यः)** । बाह्वादेरपवादः । उडुलोमाः । आकृतिगणोयम् ॥ **अनृष्यानन्तर्ये विदादिभ्योऽञ्**[2] ।४।१।११२। ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे । बिदस्य गोत्रं बैदः । बैदौ । बिदाः । पुत्रस्यापत्यं पौत्रः । पौत्रौ । यञञोश्चेति सूत्रे प्रवराध्यायप्रसिद्धं गोत्रं । तेनेह न । पौत्राः । एवं दौहित्रादयः ॥ **शिवादिभ्योऽण्**[3] ।४।१।११२। अपत्ये । शैवः । गाङ्गः ॥ **ऋष्य-**

१ बाहु, उपबाहु, उपवाकु, निवाकु, शिवाकु, वटाकु, उपविन्दु, वृषली, वृकला, चूडा, बलाका, मूषिका, कुशला, छगली, धुवका, ध्रुवका, सुमित्रा, दुर्मित्रा, पुष्करसद्, अनुहाद्, देवशर्मन्, अग्निशर्मन्, भद्रशर्मन्, सुशर्मन्, कुनामन्, सुनामन्, पञ्चन्, सप्तन्, अष्टन्, अमितौजसः सुलोपश्च, सुधावन्, उदञ्चु, मात्र, सिरस्, शराविन्, मरीचिन्, क्षेमवृद्धिन्, शृंखलतोदिन्, खरनादिन्, नगरमर्दिन्, प्राकारमर्दिन्, लोमन्, अजीगर्त, कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, गद, प्रद्युम्न, उदङ्क, उदक, संज्ञायाम्, संभूयोऽम्भसः सलोपश्च, आकृतिगणोऽयम् । तेन सात्यकिः, जाङ्घिः, ऐन्द्रशर्मिः, आजधेनविः, इति बाह्वादिः । २ विद, उर्व, कश्यप, कुशिक, भरद्वाज, उपमन्यु, किलात, किंदर्भ, विश्वनर, ऋष्टिषेण, ऋतभाग, हर्यश्व, प्रियक, आपस्तंब, कूचवार, शरद्वत, शुनक, धेनु, गोपवन, शिग्रु, बिंदु, भाजक, भाजन, अश्ववतान, श्यामक, श्यामाक, श्यावलि, श्यापर्ण, हरित, किंदास, बह्यस्क, अर्क, लूष, वध्योग, विष्णुवृद्ध, प्रतिबोध, रथीतर, रथन्तर, गविष्ठिर, निषाद, शबर, अलस, मठर, सूपाक, मृदु, पुनर्भू, पुत्र, दुहितृ, ननान्दृ, परस्त्री, परशुं च । इति बिदादिः । ३ शिव, प्रोष्ठि, प्रोष्ठिक, पड, जम्भ, भूरि, दण्ड, कुठार, ककुभ, भ्रम, अनभिम्लान, कोहित, सुख, सन्धि, मुनि, ककुत्स्थ, कहोड, कोहड, कहूषय, कहय, रोध, कपिञ्जल, खञ्जनवतण्ड, तृण, कर्ण, क्षीर, ह्रद, जलह्रद, परिल, पीष्ट, हहय, गोपिका, कपालिका, जटिलिका, बधिरिका, मञ्जिष्ठा, वृष्णिक, खञ्जार, खञ्जाल, रेख, लेख, रिख, आलेखन, विश्रवण, रवण, वर्तनाक्ष, ग्रीवाक्ष, पिटक, ऋक्षाक, नभाक, ऊर्णनाभ, जरत्कारु, पुरोहितिका, सुरोहिका, आर्यश्वेत, सुपिष्ट, मसुर, कर्ण, मयूरकर्ण, खटूरक, तक्षण, ऋष्टिषेण, गङ्गा, विपाश, यस्क, लह्य, दुह्य, अयस्थूण, तृणकर्ण, पर्ण, भलन्दन, विरूपाक्ष, भूमि, इला, सपत्नी, द्व्यचो नद्या, त्रिवेणी, त्रिवर्णं च । इति शिवादिः ।

न्धकवृष्णिकुरुभ्यश्च ।४।१।११४। ऋषिभ्यः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः । श्वाफल्कः । वृष्णिभ्यः । वासुदेवः । कुरुभ्यः । नाकुलः । साहदेवः ॥ **मातुरुत्संख्यासंभद्रपूर्वायाः ।४।१।११५।** संख्यादिपूर्वस्य मातृशब्दस्य उदादेशः स्यादण् प्रत्ययश्च । द्वैमातुरः । षाण्मातुरः ।भाद्रमातुरः ॥ **स्त्रीभ्यो ढक् ।४।१।१२०।** स्त्रीप्रत्ययान्तेभ्यो ढक् । वैनतेयः ॥ **कन्यायाः कनीन च ।४।१।११६।** चादण् । कानीनो व्यासः कर्णश्च ॥ **राजश्वशुराद्यत् ।६।४।१३७ (राज्ञो जातावेव) ॥ ये चाभावकर्मणोः ।६।४।१६८।** यादौ तद्धिते अन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातावेवेति किम् ॥ **अन् ।६।४।१६७।** प्रकृत्याणि परे । राजनः ॥ **क्षत्राद्धः ।४।१।१३८।** क्षत्रियः । जाताविल्येव । क्षात्रिरन्यः ॥ **रेवत्यादिभ्यष्ठक् ।४।१।१४६। ठस्येकः ।७।३।५०।** अङ्गात्परस्य ठस्येकादेशः । रैवतिकः ॥ **गोत्रे कुञ्जादिभ्यश्च्फञ् ।४।१।९८। व्रातच्फञोरस्त्रियाम् ।५।३।११३।** व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यप्रत्ययः स्यात् । कौञ्जायन्यः । कौञ्जायन्यौ । बहुत्वे लुग्वक्ष्यते । व्राध्नायन्यः ॥ **नडादिभ्यः फक् ।४।१।९९।**

---

१ रेवती, अश्वपाली, मणिपाली, द्वारपाली, वृकवञ्चिन्, वृकबन्धु, वृकग्राह, कर्णग्राह, ककुदाक्ष, चामरग्राह, कुक्कुटाक्ष, । इति रेवत्यादिः । २ कुञ्ज, ब्रध्न, शङ्ख, भस्मक, गण, लोमन्, शठ, शाक, शुण्डा, शुभ, विपाश, स्कन्द, स्कम्भ, इति कुञ्जादिः । ३ नड, चर, बक, मुञ्ज, इतिक, इतिश, उपक, एक, लमक, शलङ्कु, शलङ्कुंच, सप्तल, वाजप्य, तिक, अग्निशर्मन्, वृषगण, प्राण, नर, सायक, दास, मित्र, द्वीप, पिङ्गर, पिङ्गल, किंकर, किङ्कल, काश्यप, कातर, कातल, काश्य, काव्य, अज, अमुष्य, कृष्णरणौ, ब्राह्मणवासिष्ठे, अमित्र, लिगु, चित्र, कुमार, क्रोष्टु, क्रोष्टं च, लोह, दुर्ग, स्तम्भ, शिंशपा, अग्रतृण, शकर, सुमनस्, सुमत, निमत, ऋच, जलंधर, अध्वर, युगंधर, हंसक, दण्डिन्, हस्तिन्, पिण्ड, पञ्चाल, चमसिन्, सुकृत्य, स्थिरक, ब्राह्मण, चटक, बदर, अश्वल, खरप, लङ्क, इन्ध, अस्त्र, कामुक, ब्रह्मदत्त, उदुम्बर, शोण, अलोह, दण्ड । इति नडादिः ॥

गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥ **अश्वादिभ्यः फञ्।**[1] ४।१।११०। गोत्रे । आश्वायनः ॥ **इतश्चानिञः ।४।१।१२२।** इकारान्ताद्ध्यचोऽपत्ये ढक् न त्विञन्तात् । दौलेयः । नैधेयः । आत्रेयः । आत्रेयौ ॥ **अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ।२।४।६५।** एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् तत्कृतबहुत्वे न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥ **शुभ्रादिभ्यश्च**[2] **।४।१।१२३।** शौभ्रेयः ॥ **कल्याण्यादीनामिनङ्**[3] **।४।१।१२६।** एषामिनङ् स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥ **कुलटाया वा ।४।१।१२७।** इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटेयः । कौलटिनेयः । सती भिक्षुक्यत्र कुलटा ॥ **चटकाया ऐरक् ।४।१।१२८। (चटकादिति वाच्यम्)** । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति सिध्यति । चटकस्य

---

१ अश्व, अश्मन्, शङ्ख, शूद्रक, बिद, कुट, रोहिण, खर्जूर, पिञ्जूल, भडिल, भण्डिल, भडित, भण्डित, प्रहृत, रामोद, ग्रीवाकोश, काण, गोलाङ्क, अर्क, स्वन, वन, पाद, चक्र, कुल, पूल, श्रविष्ठा, वीक्ष, पविन्द, परित्र, गोमिन, श्याम, धूम, धूम्र, वाग्मिन्, विश्वानर । कुट, शपात्रेये, जन, जड, खड, ग्रीष्म, अर्ह, केत, विशय, विशाल, गिरि, चपल, चुप, दास, बैल्य, प्राच, आनुदुह्य, पुंसिजाते, अर्जुन, सुमनस्, दुर्मनस्, नम, क्षान्त, ध्वान, आत्रेयभारद्वाजे, भारद्वाजात्रेये, उत्स, आतव, कितव, शिव, खदिर । इत्यश्वादिः । २ शुभ्र, विष्ट, पुर, ब्रह्मकृत, शतद्वार, शलाथल, शकलाभ्र, लेखाभ्र, विकास, रोहिणी, रुक्मिणी, धर्मिणी, दिश, शालूक, अजबस्ति, शकन्धि, विमातृ, विधवा, शुक, विश, देवतर, शकुनि, शुक्र, उग्र, शबल, बन्धकी, सुकण्डु, विश्व, अतिथि, गोदन्त, कुशाम्ब, मकष्टु, शान्ता, इर, यवष्टुरिक, सुनामन्, लक्षणश्यामयोर्वासिष्ठे, गोधा, कृकलास, अणीव, प्रवाहण, भरत, भरम, वृकण्डू, कर्पूर, इतर, अन्यतर, आलीढ, सुदत्र, सुदक्ष, सुवक्षस्, सुदाकन्, कद्रु, तुदव, अशाय, कुमारिका, कुठारिका, किशोरिका, अम्बिका, जिह्माशिन्, परिधि, वायुदत्त, शकल, शलाका, स्वध्वर, कुबेरिका, अशोका, गन्धपिङ्गला, खण्डोन्मत्ता, अनुवृष्टिन्, जरतिन्, बलीवर्दिन्, विग्र, बीज, जीष, श्वन्, अश्मन्, अश्व । इति शुभ्रादिराकृतिगणः ॥ ३ कल्याणी, सुभगा, बन्धकी, अनुदृष्टि, अनुसृति, जरती, बली, वदी, ज्येष्ठा । कनिष्ठा, मध्यमा, परस्त्री । इति कल्याण्यादिः ॥

चटकाया वा अपत्यं चाटकैरः ॥ (**स्त्रियामपत्ये लुग् वक्तव्यः**)। तयोरेव स्त्र्यपत्यं चटका ॥ **गोधाया ढ्रक्** ।४।१।१२९। गौधेरः । शुभ्रादित्वाड्ढक्। गौधेयः ॥ **क्षुद्राभ्यो वा** ।४।१।१३१। अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो ढ्रक् वा। पक्षे ढक्। काणेरः। काणेयः। दासेरः । दासेयः ॥ **पितृष्वसुश्छण्**। ४।१।१३२। अणोऽपवादः। पैतृष्वस्रीयः॥ **ढकि लोपः** ।४।१।१३३। पितृष्वसुर्यदुक्तं तदस्यापि स्यात्। मातृष्वस्रीयः । मातृष्वसेयः ॥ **कुलात्खः** ।४।१।१३९। कुलीनः। तदन्तादपि । उत्तरसूत्रे अपूर्वपदादिति लिङ्गात्। आढ्यकुलीनः॥ **अपूर्वपदादन्यतरस्यां यड्ढकञौ** ।४।१।१४१। कुलादित्येव। पक्षे खः। महाकुलः। महाकुलीनः॥ **दुष्कुलाड्ढक्** ।४।१।१४२। वा। पक्षे खः। दौष्कुलेयः। दुष्कुलीनः॥ **स्वसुश्छः** ।४।१।१४३। स्वस्रीयः॥ **भ्रातुर्व्यच्च** ।४।१।१४४। चाच्छः। भ्रातृव्यः। भ्रात्रीयः ॥ **मनोर्जातावञ्यतौ षुक् च** ।४।१।१६१। समुदायार्थो जातिः। मानुषः। मनुष्यः॥ (**तक्ष्णोऽणुपसंख्यानम्**)॥ **षपूर्वहन्धृतराज्ञामणि** ।६।४।१३५। एषामणि तद्धितेऽनोकारलोपः। ताक्ष्णः॥ **तिकादिभ्यः फिञ्** ।४।१।१५४। तैकायनिः॥ **वृद्धिर्यस्याचामादिस्तद्वृद्धम्** ।१।१।७३। यस्य समुदायस्याचां मध्ये आदिवृद्धिस्तद्वृद्धसंज्ञं स्यात्॥ **उदीचां वृद्धादगोत्रात्** ।४।१।१५७। आम्रगुप्तायनिः। प्राचां तु आम्रगुप्तिः ॥ **प्राचामवृद्धात्फिन्बहुलम्** ।४।१।१६०। ग्लुचुकायनिः॥ **जनपदशब्दात्क्षत्रियादञ्**। ४।१।१६८। जनपदक्षत्रिययोर्वाचकादञ् अपत्ये। पाञ्चालः ॥ **क्षत्रियसमानशब्दाज्जनपदात् तस्य राजन्यपत्यवत्**। पञ्चालानां राजा पाञ्चालः॥ (**पूरोरण्**) पौरवः ॥ **द्व्यञ्मगधकलिङ्गसूरमसादण्** ।४।१।१७०। द्व्यच्। आङ्गः। वाङ्गः। मागधः। (**पाण्डोर्ड्यण्**) पाण्ड्यः ॥ **वृद्धेत्कोशलाजादाञ्ञ्यङ्**।

---

१ तिक, कितव, संज्ञा, बाला, शिखा, उरस्, शाठ्य, सैन्धव, यमुन, रूप्य, ग्राम्य, नील, अमित्र, गोकक्ष, कुरु, देवरथ, तैतिल, औरस, कौरव्य, भौरिकी, मौलिकी, मौलीकी, चौपत, चैटयत, शीकयत, क्षैतयत, ध्वाजवत्, चन्द्रमस्, शुभ, गङ्गा, वरेण्य, सुयामन्, आरब्ध, बाह्यक, खल्प, वृष, लोमक, उदन्य, यज्ञ, इति तिकादिः॥

४।१।१७१। वृद्धात् । आम्बष्ठ्यः । इत् । आवन्त्यः । कौशल्यः । अजादस्यापत्यं आजाद्यः ॥ **कुरुनादिभ्यो ण्यः** ।४।१।१७२। कौरव्यः । नैषध्यः ॥ **ते तद्राजाः** ४।१।१७४। अञादयस्तद्राजसंज्ञाः स्युः ॥ **तद्राजस्य बहुषु तेनैवास्त्रियाम्** । २।४।६२। बहुष्वर्थेषु तद्राजस्य लुक् तत्कृते बहुत्वे न तु स्त्रियाम् । पञ्चाला इत्यादि ॥ **कम्बोजाल्लुक्**[1] ।२।२।१७५। तद्राजस्य । कम्बोजः कम्बोजौ । (**कम्बोजादिभ्य इति वक्तव्यम्**) चोलः । शकः । केरलः । यवनः ॥ **अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे** ।४।१।७८। त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम् । गोत्रे यावणिञौ विहितौ अनार्षौ तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः । 'यङश्चाप्' कुमुदगन्धेर्गोत्रापत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् । वासिष्ठी । गुरूपोत्तमयोः किम् । औपगवी । गोत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री । इत्यपत्याधिकारः ॥

तेन रक्तं रागात् ।४।२।१। कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ॥ **लाक्षारोचनाट्ठक्** ।४।२।२। लाक्षिकः । रौचनिकः ॥ (**शकलकर्दमाभ्यामुपसंख्यानम्**) शाकलिकः । कार्दमिकः ॥ (**नील्या अन्**) । नील्या रक्तं वस्त्रं नीलम् ॥ (**पीतात्कन्**) । पीतकम् ॥ (**हरिद्रामहारजताभ्यामञ्**) । हारिद्रम् । माहारजतम् ॥ **नक्षत्रेण युक्तः कालः** ।४।२।१३। **तिष्यपुष्ययोर्नक्षत्राणि यलोपः** ।४।२।३। पुष्येण युक्तं पौषमहः ॥ **लुबविशेषे** ।४।२।१४। पूर्वेण विहितस्य लुप् । षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ॥ **दृष्टं साम** ।४।२।११७। तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥ **वामदेवाड्ड्यड्ड्यौ** ।४।२।२९। वामदेवेन दृष्टं वामदेव्यम् ॥ **परिवृतो रथः** ।४।२।१०। वस्त्रेण परिवृतो वास्त्रो रथः ॥ **तत्रोद्धृतममत्रेभ्यः** ।४।२।१४। शरावे उद्धृतः शाराव ओदनः ॥ **संस्कृतं भक्षाः** । ४।२।१६। सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा भक्षाः ॥ **शूलोखाद्यत्** ४।२।७१। अणोऽपवादः । शूले संस्कृतं

---

१ कम्बोज, चोल, केरल, शक, यवन । इति कम्बोजादिः ॥

शूल्यं मांसम्। उख्यम्॥ **दध्नष्ठक्** ।४।२।१८। दध्नि संस्कृतं दाधिकम्॥ **सास्मिन्पौर्णमासीति** ।४।२।२१। इतिशब्दात्संज्ञायामिति लभ्यते। पौषी पौर्णमासी अस्मिन्पौषो मासः॥ **सा॑ऽस्य देवता** ।४।२।२४। इन्द्रो देवताऽस्यैन्द्रं हविः। पाशुपतम्। बार्हस्पतम्। त्यज्यमानद्रव्य उद्देश्यविशेषो देवता मन्त्रस्तुत्या च॥ ऐन्द्रो मन्त्रः॥ **कस्येत्** ।४।२।२५। कशब्दस्य ईकारादेशः स्यात्प्रत्ययसंनियोगेन। यस्येति लोपात्परत्वादादिवृद्धिः। को ब्रह्मा देवताऽस्य कायं हविः। श्रीर्देवतास्य श्रायम्॥ **शुक्राद्घन्** ।४।२।२६। शुक्रियम्॥ **सोमाट्ट्यण्** ।४।२।३०। सौम्यम्। **वाय्वृतुपित्रुषसो यत्** ।४।२।३१। वायव्यम्। ऋतव्यम्॥ **रीङ् ऋतः**। ।७।४।२७। अकृद्यकारेऽसार्वधातुकयकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। 'यस्येति च'। पित्र्यम्। उषस्यम्॥ **द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च** ।४।२।३२। चाद्यत्। द्यावापृथिवीयम्। द्यावापृथिव्यम्। शुनासीरीयम्। शुनासीर्यम्॥ **महाराजप्रोष्ठपदाट्ठञ्** ।४।२।३५। माहाराजिकम्। प्रौष्ठपदिकम्॥ **देवताद्वन्द्वे च** ।७।३।२१। अत्र पूर्वोत्तरपदयोराद्यचो वृद्धिर्ञिति णिति किति च। आग्निमारुतम्॥ **नेन्द्रस्य परस्य** ।७।३।२२। सौमेन्द्रः। परस्य किम्। ऐन्द्राग्नः॥ **दीर्घाच्च वरुणस्य** ।७।३।२३। न वृद्धिः। ऐन्द्रावरुणम्। दीर्घात्किम्। आग्निवारुणीमनड्वाहीमालभेत॥ **पितृव्यमातुलमातामहपितामहाः** ।४।२।३६। एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। मातुः पिता मातामहः। पितुः पिता पितामहः॥ **तस्य समूहः** ।४।२।३७। काकानां समूहः काकम्। बकानां समूहः बाकम्॥ **भिक्षादिभ्योऽण्**[2] ।४।२।३८। भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह भस्याढ इति पुंवद्भावे कृते॥ **इनण्यनपत्ये** ।६।४।१६४। अनपत्यार्थेऽणि इन्प्रकृत्या। तेन नस्तद्धिते इति टिलोपो न। युवतीनां समूहो यौवतम्[3]॥ **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजा-**

---

१ सा इति प्रकृतं संज्ञासंबद्धमिति पुनः साग्रहणं कृतम्॥ २ भिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन्, सहस्र, युवति, पदाति, पद्धति, अथर्वन्, दक्षिणा, भरत, विषय, श्रोत्र, इति भिक्षादिः। ३ युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः। पुंवद्भावात्तिप्रत्ययनिवृत्तिः। 'अन्' इति प्रकृतिभावः॥

ढञ् ।४।२।३९। ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य चेति यलोपे प्राप्ते ॥ (**प्रकृत्या अके राजन्यमनुष्ययुवानः**) । राजन्यकम् । मानुष्यकम् ॥ (**वृद्धाच्चेति वक्तव्यम्**) । वार्धकम् ॥ **केदाराद्यञ्च** ।४।२।४०। चाड्ढञ् । कैदार्यम् । कैदारकम् ॥ (**गणिकाया यञ् वक्तव्यः**) । गाणिक्यम् ॥ **ठञ् कवचिनश्च** ।४।२।४१। चात्केदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥ **ग्रामजनबन्धुभ्यस्तल्** ।४।२।४३। ग्रामता । जनता । बन्धुता । तलन्तं स्त्रियाम् ॥ (**गजसहायाभ्यां चेति वक्तव्यम्**) । गजता । सहायता ॥ (**अह्नः खः क्रतौ**) । अहीनः क्रतुः ॥ **अचित्तहस्तिधेनोष्ठक्** ।४।४।४७। **इसुसुक्तान्तात्कः** ।७।२।५१। इस् उस् उक् त एतदन्तात्परस्य ठस्य कः । साक्तुकम् । हास्तिकम् । धैनुकम् ॥ **केशाश्वाभ्यां यञ्छावन्यतरस्याम्** ।४।४।४८। पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् ॥ **पाशादि[1]भ्यो यः** ।४।२।४९। पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥ **खलगोरथात्** ।४।२।५०। खल्या । गव्या । रथ्या ॥ **इनित्रकट्यचश्च** ।४।२।५१। खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥ (**खलादि[2]भ्य इनिर्वक्तव्यः**) ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥ **तदस्यां प्रहरणमिति क्रीडायां णः** ।४।२।५७। दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ॥ **घञः सास्यां क्रियेति ञः** ।४।२।७०। घञन्तात् क्रियावाचिनः प्रथमान्तादस्यामित्यर्थे स्त्रीलिङ्गे ञप्रत्ययः ॥ **श्येनतिलस्य पाते ञे** ।६।३।७१। अनयोर्मुम् स्यात् ञप्रत्यये परे पातशब्दे उत्तरपदे । श्यैनम्पाता मृगया । तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां दाण्डपाता तिथिः ॥ **तदधी[3]ते तद्वेद** ।४।२।५९। **नय्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्** ।७।३।३। पदान्ताभ्यां यकारवकाराभ्यां परस्याचो

---

१ पाश, तृण धूम, वात, अङ्गार, पाटल, पोत, गल, पिटक, पिटाक, शकट, हल, नट, वन, इति पाशादिः । २ खल, डाक, कुटुम्ब, इति खलादिराकृतिगणः । तेन शाकिनीत्यपि सिद्धम् । ३ द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । द्विस्तद्ग्रहणं चाधीयाने विदुषि च प्रत्येकं विधानार्थम् ।

न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । व्याकरणमधीते वेत्ति वा वैयाकरणः ॥ **क्रमादिभ्यो वुन्** ।४।२।६१। क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥ **क्रतूक्थादिसूत्रान्ताट्ठक्** ।४।२।६०। क्रतुविशेषवाचिनामेव ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषः तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा औक्थिकः ॥ **(मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते)** नैयायिकः । वार्तिकः । लौकायतिकः ॥ **(सूत्रान्तात्तु अकल्पादेरेवेष्यते)** सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ **(विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्)** । वायसविद्यिकः । गौलक्षणिकः । पाराशरकल्पिकः ॥ **(अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम्)** आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविद्या तामधीते वेत्ति वा त्रैविद्यः ॥ **तदस्मिन्नस्तीति देशे तन्नाम्नि** ।४।२।६७। उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः ॥ **तेन निर्वृत्तम्** ।४।२।६८। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥ **तस्य निवासः** ।४।२।६९। शिबीनां निवासो देशः शैबः ॥ **अदूरभवश्च** ।४।२।७०। विदिशाया अदूरभवं वैदिशम् ॥ **वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्व-**

---

१ उक्थ, लोकायत, न्याय, न्यास, पुनरुक्त, निरुक्त, निमित्त, द्विपद, ज्योतिष, अनुपद, अनुकल्प, यज्ञ, धर्म, चर्चा, क्रमेतर, संहिता, पदक्रम, संघट्ट, वृत्ति, परिषद्, संग्रह, गुण, गण, आयुर्वेद । इत्युक्थादिः । २ अरीहण, द्रुघण, द्रुहण, भगल, उलन्द, किरण, सांपरायण, क्रौष्ट्रायण, औष्ट्रायण, त्रैगर्तायण, मैत्रायण, भस्त्रायण, वैमतायन, गौमतायन, सौमतायन, सौसायन, धौमतायन, ऐन्द्रायण, कौन्द्रायण, खाडायन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश, उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, काशकृत्स्न, चाम्बवत्, शिंशपा, रैवत, बिल्व, सुयज्ञ, शिरीष, बधिर, जम्बु, खदिर, सुशर्मन्, भलतृ, भलन्दन, खण्डु, कलन, यज्ञदत्त । इत्यरीहणादिः । ३ कृशाश्व, अरिष्ट, अरिश्म, वेश्मन्, विशाल, लोमश, रोमश, रोमक, शवल, कूटवर्चल, सुवर्चल, सुकर, सूकर, प्रतर, सदृश, पुराग, पुरग, मुख, धूम, अजिन, विनत, अवनत, विकुस्यास, पराशर, अरुस, अयस, मौद्गल्य, यूकर । इति कृशाश्वादिः ।

ऋश्य[1]कुमुद[2]काश[3]तृण[4]प्रेक्षा[5]ऽश्म[6]सखि[7]संकाश[8]बल[9]पक्ष[10]कर्ण[11]सुतंगम[12]प्रगदिन्[13]व-

१ ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात, विधान, निबद्ध, विबद्ध, परिगूढ, उपगूढ, असनि, सित, मत, वेश्मनू, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर, शर्करा, अनडुह्, अरडु, परिवंश, वेणु, वीरण, खण्ड, दण्ड, परिवृत्त, कर्दम, अंश, इत्यृश्यादिः ॥ २ कुमुद, शर्करा न्यग्रोध, इक्कट, संकट, कङ्कट, गर्त, बीज, परिवाप, निर्यास, शकट, कच, मधु, शिरीष, अश्व, अश्वत्थ, बल्व, यवास, कूप, विकङ्कट, दशग्राम, इति कुमुदादिः ॥ ३ काश, पाश अश्वत्थ, पलाश, पीयूक्षा, चरण, वास, नड, वन, कर्दम, कच्छूल, कङ्कट, गुहा, विस, तृण, कर्पूर, बर्वर, मधुर, ग्रह, कपित्थ, जतु, शीपाल, इति काशादिः ॥ ४ तृण, नड, मूल, वन, पर्ण, वराण, विल, पुल, फल, अर्जुन, अर्ण, सुवर्ण, बल, चरण, बुस, इति तृणादिः ॥ ५ प्रेक्षा, हलका, बन्धुका, ध्रुवका, क्षिपका, न्यग्रोध, इक्कट, कङ्कट, सङ्कट, कट, कूप, बुक, पुक, पुट, मह, परिवाप, यवास, ध्रुवका, गर्त, कूपक, हिरण्य, इति प्रेक्षादिः ॥ ६ अश्मन्, यूथ, ऊष, मीन, नद, दर्भ, वृन्द, गुद, खण्ड, नग, शिखा, कीट, पाम, कन्द, कान्द, कुल, गह्, गुड, कुण्डल, पीन, गुह, इत्यश्मादिः ॥ ७ सखि, अग्निदत्त, वायुदत्त, सखिदत्त, गोपिल, भल्ल, पाल, चक्र, चक्रवाक, छगल, अशोक, करवीर, वासव, वीर, वज्र, कुसीरक, सीहर, सरक, सरस, सरम, समर, समल, सुरस, सेह, तमाल, कदल, सप्तल, इति सख्यादिः ॥ ८ संकाश, कपिल, काश्मीर, समीर, शूरसेन, सरक, शूर, सुपन्थिन्, पन्थ च, यूथ, अंश, अङ्ग, नासा, पलित, अनुनाश, अश्मन्, कूट, मलिन, दश, कुम्भ, शीर्ष, वितर, समल, सीर, पञ्जर, मन्थ, नल, रोमन्, पुलिन, सुपरि, कटिप, सकर्णक, वृष्टि, तीर्थ, अगस्ति, विकर, नासिका, इति संकाशादिः ॥ ९ बल, चुल, नल, दल, वट, लकुल, उरल, पुस, मूल, उल, डुल, वन, कुल, इति बलादिः ॥ १० पक्ष, तुच्छ, तुष, तुण्ड, अण्ड, कम्बलिका, बलिक, चित्र, अस्ति, पथिन्पन्थ च, कुम्भ, सीरक, सरक, सकल, सरस, समल, अतिश्वन्, रोमन्, लोमन्, हस्तिन्, मकर, लोमक, शीर्ष, निवात, पाक, सिंहक, अंकुश, सुवर्णक, हंसक, हिंसस, कुत्स, बिल, खिल, यमल, हस्तकला, सकर्णक, इति पक्षादिः ॥ ११ कर्ण, वसिष्ठ, अर्क, अर्कलूष, द्रुपद, आनडुह्य, पाञ्चजन्य, स्फिच्, कुम्भी, कुन्ती, जित्वन्, जीवन्त, कुलिश, आण्डीवत्, जव, जैत्र, आनक, इति कर्णादिः ॥ १२ सुतङ्गम, मुनिचित, विप्रचित्त, महाचित्त, महापुत्र, स्वन, श्वेत, खण्डिक, शुक, विग्र, बीजवापिन्, अर्जुन, श्वन्, अजिर, जीव, खडिक, कर्ण, विग्रह, इति सुतङ्गमादिः ॥ १३ प्रगदिन्, मगदिन्, मददिन्, कबिल, खण्डित, गदित, चूडार, मडार, मन्दार, कोविदार, इति प्रगद्यादिः ॥

[1]वराहकुमुदादिभ्यः ।४।३।२०।सप्तदशभ्यः सप्तदश क्रमात्स्युश्चातुरर्थ्याम्। अरीहणादिभ्यो वुञ्। अरीहणेन निर्वृत्तमारीहणकम्। कृशाश्वादिभ्यश्छण्। कार्शाश्वीयः। ऋश्यादिभ्यः कः। ऋश्यकम्। कुमुदादिभ्यष्ठच्। कुमुदिकम्॥ काशादिभ्य इलः। काशिलः। तृणादिभ्यः सः। तृणसम्। प्रेक्षादिभ्य इनिः। प्रेक्षी। अश्मादिभ्यो रः। अश्मरः। सख्यादिभ्यो ढञ्। साखेयम्। संकाशादिभ्यो ण्यः। सांकाश्यम्। बलादिभ्यो यः। बल्यम्। पक्षादिभ्यः फक्। पाक्षायणः। पथःपन्थ च। पान्थायनः। कर्णादिभ्यः फिञ्। कार्णायनिः। सुतंगमादिभ्य इञ्। सौतंगमिः। प्रगदिनादिभ्यो ञ्यः। प्रागद्यः। वराहादिभ्यः फक्। वाराहकः। कुमुदादिभ्यष्ठक्। कौमुदिकः॥ **जनपदे लुप्** ।४।२।८१। जनपदे वाच्ये चातुरर्थिकस्य लुप्॥ **लुपि युक्तवद्व्यक्तिवचने** ।१।२।५१। लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। अङ्गाः। कलिङ्गाः॥ **[3]वरणादिभ्यश्च** ।४।२।८२। अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥ **शर्कराया वा** ।४।२।८३। अस्याचातुरर्थिकस्य लुप्स्यात्॥ **ठक्छौ च** ।४।२।८४। शर्कराया एतौ स्तः। कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ। वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण्। तस्य लुब्विकल्पः। षड् रूपाणि। शर्करा। शार्करिकम्। शार्करम्। शर्करियम्। शर्करिकम्। शार्करकम्॥ **नद्यां मतुप्** ।४।२।८५। चातुरर्थिकः। इक्षुमती॥ **कुमुदनडवेतसेभ्यो ड्मतुप्** ।४।२।८७॥ **झयः** ।८।२।१०। मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥ **मादुपधायाश्च मतोर्वोऽयवादिभ्यः** ।८।२।९। मवर्णावर्णा-

---

१ वराह, पलाश, शिरीष, पिनद्ध, निबद्ध, बलाद, स्थूल, विदग्ध, विजग्ध, विभग्न, निमग्न, बाहु, खदिर, शर्करा, इति वराहादिः॥ २ कुमुद, गोमथ, रथकार, दशग्राम, अश्वत्थ, शाल्मलि, शिरीष, मुनिस्थल, कुण्डल, कूट, मधुकर्ण, घास, कुन्द, शुचि, कर्ण, इति कुमुदादिः॥ ३ वरणा, शृङ्गी, शाल्मलि, शुण्डी, सायाण्डी, पर्णी, ताम्रपर्णी, गोद, आलिङ्ग्यायन, जानपदी, जम्बू, पुष्कर, चम्पा, पम्पा, वल्गु, उज्जयिनी, गया, मथुरा, तक्षशिला, उरसा, गोमती, वलभी, इति वरणादिः॥ ४ यव, दल्मि, ऊर्मि, भूमि, कृमि, कुञ्च, वशा, द्राक्षा, ध्राक्षा, ध्रजि, ध्वजि, निजि, सञ्जि, हरित, ककुद्, मरुत्, गरुत्, इक्षु, द्रु, मधु, आकृतिगणोऽयम्॥

न्तान्मवर्णाऽवर्णोपधायाश्च यवादिवर्जितात्परस्य मतोर्मस्य वः । वेतस्वान् ॥ **नडशादाड्ड्वलच्** ।४।२।८८। नड्वलः । शाद्वलः ॥ **शिखाया वलच्** ।४।२।८९। शिखावलः ॥ **उत्करादिभ्यश्छः** ।४।२।९०। उत्करीयम् ॥ **नडादीनां कुक् च** ।४।२।९१। नडकीयम् ॥ **कुञ्चा ह्रस्वत्वं च** । क्रुञ्चकीयः ॥ (**तक्षन्नलोपश्च** ।) तक्षकीयः । इति चातुरर्थिकाः ॥

शेषे[1] ।४।२।९२। अपत्यादिचातुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । तस्य विकार इत्यतः प्राक् शेषाधिकारः ॥ **राष्ट्रावारपाराद्घखौ** ।४।२।९३। आभ्यां घखौ स्तः । राष्ट्रे जातादि राष्ट्रियः । अवारपारीणः ॥ (**अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्**) । अवारीणः । पारावारीणः । इह प्रकृतिविशेषात् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते । तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥ **ग्रामाद्यखञौ** ।४।२।९४। ग्राम्यः । ग्रामीणः ॥ **नद्यादिभ्यो ढक्**[2] ।४।२।९७। नादेयम् । माहेयम् । वाराणसेयम् ॥ **दक्षिणापश्चात्पुरसस्त्यक्** ।४।२।९८। दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ **द्युप्रागपागुदक्प्रतीचो यत्** ।४।२।१०१। दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥ **अव्ययात्त्यप्** ।४।२।१०४। (**अमेहक्वतसित्रेभ्य एव**[3]) । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः ॥ (**त्यब् नेर्ध्रुव इति वाच्यम्**) । नित्यः । **निसो गते** ॥ **ह्रस्वात्तादौ तद्धिते** ।८।३।१०१। ह्रस्वादिणः सस्य षस्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः । (**अरण्याण्णः**) । आरण्याः सुमनसः ॥ **दूरादेत्यः** । दूरेत्यः ॥ (**उत्तरादाहञ्**) औत्तराहः ॥ **ऐषमोह्यःश्वसोऽन्यत-**

---

१ इदं लक्षणं चाधिकारश्च ॥ २ नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकौशाम्बी, काशपरी, काशफरी, खादिरी, पूर्वचरी, पाठा, माया, शाल्वा, दार्वा, सेतकी, वडवाया वृषे, इति नद्यादिः ॥ ३ अमाशब्दः समीपवाची स्वरादिः अमा । समीपे भव इत्यर्थः ।

रस्याम् ।४।२।१०५। एभ्यस्त्यब्वा। पक्षे वक्ष्यमाणौ त्युट्युलौ। ऐषमस्त्यम्। ऐषमस्तनम्। ह्यस्त्यम्। ह्यस्तनम्। श्वस्त्यम्। श्वस्तनम्। पक्षे शौवस्तिकं वक्ष्यते ॥ **वृद्धाच्छः** ।४।२।११४। शालीयः ॥ **त्यदादीनि च** ।१।१।७४। वृद्धसंज्ञानि स्युः। तदीयः। वा नामधेयस्य वृद्धसंज्ञा। देवदत्तीयः। दैवदत्तः। भावत्कः ॥ **(सिति च)**। तद्धिते पूर्वं पदं स्यात्। जश्त्वम्। भवदीयः। वृद्धादित्यनुवृत्तेः शत्रन्तादणेव। भावतः ॥ **काश्यादिभ्यष्ठञ्ञिठौ** ।४।२।११६। इकार उच्चारणार्थः। काशिकी। काशिका। वैदिकी। वैदिका। **(आपदादिपूर्वपदात्कालान्तात्)**। आपदादिराकृतिगणः। आपत्कालिकी। आपत्कालिका ॥ **धन्वयोपधाद्वुञ्** ।४।२।१२१। धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात्। ऐरावतं धन्व ॥ ऐरावतकः। सांकाश्यकाम्पिल्यशब्दौ वुञ्छणादिसूत्रेण ण्यन्तौ। सांकाश्यकः। काम्पिल्यकः ॥ **नगरात्कुत्सनप्रावीण्ययोः** ।४।२।१२८। कुत्सिते प्रावीण्ये च नगरशब्दाद्वुञ् स्यात्। नागरकश्चौरः शिल्पी वा। एतयोः किम्। नागरा ब्राह्मणाः ॥ **अरण्यान्मनुष्ये** ।४।२।१२९। वुञ् स्यात्। औपसंख्यानिकणस्यापवादः। **(पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम्)**। आरण्यकः पन्थाः। अध्यायो न्यायो विहारो मनुष्यो हस्ती वा ॥ **गर्तोत्तरपदाच्छः** ।४।२।१३०। देश इत्येव। वृकगर्तीयम् ॥ **गहादिभ्यश्च** ।४।२।१३८। गहीयः ॥ **युष्मदस्मदोरन्यतरस्यां**

---

१ काशि, वेदि, चेदि, सांयाति, संवाह, अच्युत, मोदमान, शकुलाद, हस्तिकर्षु, कुनाम, हिरण्य, करण, गोवासन, भारङ्गी, अरिंदम, अरित्र, देवदत्त, दशग्राम, शौवावतान, युवराज, उपराज, देवराज, मोदन, सिन्धुमित्र, दासमित्र, सुधामित्र, सोममित्र, छागमित्र, मधुमित्र, इति काश्यादिः ॥ २ यद्यपि 'समानौ मरुधन्वानौ' इत्यमरेण पुंस्त्वमुक्तं तथापि 'आष्टकं नाम धन्वं' इति भाष्ये ह्रस्वपाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम् ॥ ३ गह, अन्तःस्थ, सम, विषम, मध्य, मध्येदिन, चरणे, उत्तम, अङ्ग, वङ्ग, मगध, पूर्वपक्ष, अपरपक्ष, अधमशाख, उत्तमशाख, एकशाख, समानशाख, एकग्राम, समानग्राम, एकवृक्ष, एकपलाश, इष्वग्र, इष्वनीक, अवस्यन्दन, कामप्रस्थ, खाडायन, काठेरणि, लावेरणि, सौमित्रि, शैशिरि, आसुत, देवशर्मि, श्रौती, आहिंसि, आमित्रि, व्याडि, बैजि,

खञ् च ।४।३।१। चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वायं युष्मदीयः । अस्मदीयः ॥ **तस्मिन्नणि च युष्माकास्माकौ** ।४।३।२। युष्मदस्मदोरेतावादेशौ स्तः खञि अणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ॥ **तवकममकावेकवचने** ।४।३।३। एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥ **प्रत्ययोत्तरपदयोश्च** ।७।२।९८। मपर्यन्तयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः । त्वत्पुत्रः ॥ **मध्यान्मः** ।४।३।८। मध्यमः ॥ **असांप्रतिके** ।४।३।९। मध्यशब्दादप्रत्ययः सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥ **द्वीपादनुसमुद्रं यञ्** ।४।३।१०। समुद्रसमीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥ **कालाट्ठञ्** ।४।३।११। मासिकम् । सांवत्सरिकम् । (**अव्ययानां भमात्रे टिलोपः**) सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि 'शार्वरस्य तमसो निषिद्धये' इति कालिदासः । 'अनुदितौषसरागः' इति भारविः । समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एव इति प्रामाणिकाः । तत्रजात इति यावत्कालाधिकारः ॥ **श्राद्धे शरदः** ।४।३।१२। ठञ् स्यात् । ऋत्वणोऽपवादः । शरदि भवं शारदिकं श्राद्धम् ॥ **विभाषा रोगातपयोः** ।४।३।१३। शारदिकः शारदो वा । रोग आतपो वा ॥ **निशाप्रदोषाभ्यां च** ।४।३।१४। ठञ् वा । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥ **श्वसस्तुट् च** ।४।३।१५। श्वसष्ठञ् वा तुट् च ॥ **द्वारादीनां**

आध्यश्वि, आनृशंसि, शौङ्गि, अग्निशर्मि, भौजि, वाराटकि, वाल्मीकि, क्षेमवृद्धि, आश्वत्थि, औगाहमानि, ऐकबिन्दवी, दन्ताग्र, हन्त, तन्त्वग्र, उत्तर, अनन्तर, मुखपार्श्वतसोर्लोपः । जनपरयोः कुक् च, देवस्य च, इति गहादिराकृतिगणः ।

१ इह निमित्तयोः खञणोरादेशौ प्रति यथासंख्यं न भवति किंतु स्थान्यादेशयोरेव । २ भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः । 'प्रज्ञाश्रद्धार्चादिभ्योऽण्' इति मत्वर्थीयेन व्युत्पादितः श्रद्धावान्पुरुषस्तु न गृह्यते अनभिधानात् ॥ ३ द्वार, स्वर, व्यल्कश, स्वस्ति, स्फ्यकृत, स्वादु, मृदु, श्वस्, श्वन्, स्व, इति द्वारादिः ॥

च ।७।३।४। एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥ **सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्** ।४।३।१६। सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । सन्धिवेला । सन्ध्या । अमावास्या । त्रयोदशी । चतुर्दशी । पौर्णमासी । प्रतिपत् ॥ **प्रावृष एण्यः** ।४।३।१७। प्रावृषेण्यः ॥ **वर्षाभ्यष्ठक्** ।४।३।१८। वर्षासु साधु वार्षिको वासः ॥ **सर्वत्राण् च तलोपश्च** ।४।३।२२। हेमन्तादण् तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋतवण् । हेमन्ते भवं हैमन्तं वसनम् ॥ **सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च** ।४।३।२३। सायमित्यादिभ्यश्चतुर्भ्यः अव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च । सायंभवं सायंतनम् । चिरंतनम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् ॥ दिवातनम् । (**चिरपरुत्परारिभ्यस्त्नो वक्तव्यः**) । चिरत्नम् । परुत्नम् । परारित्नम् । (**अग्रादिपश्चाड्डिमच्**) अग्रिमम् । पश्चिमम् । (**अन्ताच्च**) अन्तिमम् ॥ **विभाषा पूर्वाह्णापराह्णाभ्याम्** ।४।३।२४। आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । पौर्वाह्णिकम् । अपराह्णेतनम् । आपराह्णिकम् ॥ **तत्र जातः** ।४।३।२५। सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥ **प्रावृषष्ठप्** ।४।३।२६। एण्यस्याऽपवादः । प्रावृषिकः ॥ **प्रायभवः** ।४।३।३९। तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥ **संभूते** ।४।३।४१। स्रुघ्ने संभवति स्रौघ्नः ॥ **कोशाड्ढञ्** ।४।३।४२। कौशेयं वस्त्रम् ॥ **तत्र भवः** ।४।३।५३। स्रुघ्ने भवः स्रौघ्नः । औत्सः । राष्ट्रियः ॥ **दिगादिभ्यो यत्** ।४।३।५४। दिश्यम् । वर्ग्यम् ॥ **शरी-**

---

१ सन्धिवेला, सन्ध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत्, इति सन्धिवेलादिः ॥ २ ऋतवणोपवादः ॥ ३ प्रवर्षतीति प्रावृट् । 'नहिवृति' इति दीर्घः । तत्र भव इत्यर्थः ॥ स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः । तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इति वार्तिककृन्मतम् । भाष्यकृता तु 'मान्ताव्ययमित्याश्रित्य सायंग्रहणं प्रत्याख्यातम् ॥ ५ दिश, वर्ग, पूग, गण, पक्ष धाय्य, मित्र, मेधा, अन्तर, पथिन्, रहस, अलीक, उखा, साक्षिन्, देश, आदि, अन्त, मुख, जघन, मेष, यूथ 'उदकात्संज्ञायाम्' न्याय, वंश, वेश, काल, आकाश, इति दिगादिः ॥

रावयवाच्च ।४।३।५५। दन्त्यम् । कण्ठ्यम् ॥ **दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्** ।४।३।५६। दार्तेयम् । कलशिर्घटः । तत्रभवं कालशेयम् ॥ **ग्रीवाभ्योण् च** ।४।३।५७। चाड्ढञ् । ग्रैवेयम् । ग्रैवम् ॥ **गम्भीराञ्ञ्यः** ।४।३।५८। गम्भीरे भवं गाम्भीर्यम् ॥ **अव्ययीभावाच्च** ।४।३।५९। परिमुखे भवं पारिमुख्यम् ॥ (**परि[1]मुखादिभ्य एवेष्यते**) नेह । औपकूलः ॥ **अन्तःपूर्वपदाट्ठञ्** ।४।३।६०। अव्ययीभावादित्येव । वेश्मनि इति [2]अन्तर्वेश्यम् । तत्र भवं आन्तर्वेश्मिकम् । आन्तर्गणिकम् । [3]अध्यात्मादेष्ठञिष्यते । अध्यात्मनि भवं आध्यात्मिकम् ॥ **अनु[4]शतिकादीनां च** ।७।३।२०। एषामुभयपदवृद्धिर्ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । आकृतिगणोयम् ॥ **जिह्वामूलाङ्गुलेश्छः** ।४।३।६२। जिह्वामूलीयम् । अङ्गुलीयम् । **वर्गान्ताच्च** ।४।३।६४। कवर्गीयम् ॥ **तत आगतः** ।४।३।७४। स्रुघ्नादागतः स्रौघ्नः ॥ **ठगायस्थानेभ्यः** ।४।३।७५। शुल्कशालिकः ॥ **विद्यायोनिसंबन्धेभ्यो वुञ्** ।४।३।७७। औपाध्यायकः । पैतामहकः ॥ **ऋतष्ठञ्** ।४।३।७८। वुञोऽपवादः । हौतृकम् । मातृकम् । भ्रातृकम् ॥ **पितुर्यच्च** ।४।३।७९। चाट्ठञ् । रीङृतः । यस्येति लोपः । पित्र्यम् । पैतृकम् ॥ **गोत्रादङ्कवत्** ।४।३।८०। बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥ **हेतुम[5]नुष्येभ्योऽन्यतरस्यां रूप्यः** ।४।३।८१। समादागतं समरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । देवदत्तीयम् । देवदत्त-

---

१ परिमुख, परिहनु, पर्योष्ठ, पर्युलूखल, परिसीर उपसीर, उपस्थूण, उपकलाप, अनुपथ, अनुपद, अनुगङ्ग, अनुतिल, अनुसीत, अनुसाय, अनुसीर, अनुमाष, अनुयूप, अनुयूषि, अनुवंश, प्रतिशाख, इति परिमुखादिः ॥ २ 'नपुंसकादन्यतरस्याम्' इति समासान्तष्टच् । अध्यातम, अधिदेव, अधिभूत, इहलोक, इत्यध्यात्मादिराकृतिगणः ॥ ४ अनुशतिक, अनुहोड, अनुसंवरण, अनुसंवत्सर, अङ्गारवेणु, असिहत्य, अस्यहेति, वध्योग, पुष्करसद्, अनुहरत्, कुरुकत, कुरुपञ्चाल, उदकशुद्ध, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूमि, प्रयोग, परस्त्री, राजपुरुषात्, ष्यञ्, सूत्रनड, आकृतीगणोऽयम् । तेन अधिगम, अधिभूत, अधिदेव, चतुर्विद्या, इत्यादि इत्यनुशतिकादिः ॥ ५ मनुष्यग्रहणमहेत्वर्थं, बहुवचनं स्वरूपविधिनिरासार्थम् ॥

रूप्यम् ॥ **मयट् च** ।४।३।८२। सममयम् ॥ **प्रभवति** ।४।३।८३। हिमवतः प्रभवति हैमवती गङ्गा ॥ **विदूराञ्ञ्यः** ।४।३।८४। विदूरात्प्रभवति वैदूर्यो[1] मणिः ॥ **तद्गच्छति[2] पथिदूतयोः** ।४।३।८५। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥ **अभिनिष्क्रामति द्वारम्** ।४।३।८६। स्रुघ्नमभिगच्छति स्रौघ्नं कान्यकुब्जद्वारम् । **अधिकृत्य कृते ग्रन्थे** ।४।३।८७। शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः । शारीरक भाष्यमिति त्वभेदोपचारात् ॥ **सोऽस्य निवासः** ।४।३।८९। स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥ **तेन प्रोक्तम्** ।४।३।१०१। पाणिनिना प्रोक्तं पाणिनीयम् ॥ **पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः** ।४।३।११०। णिनिः स्यात् । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥ **कर्मन्दकृशाश्वादिनिः** ।४।३।१११। कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥ **उपज्ञाते** ।४।३।११५। पाणिनिना उपज्ञातं[3] पाणिनीयम् ॥ **तस्येदम्** ।४।३।१२०। उपगोरिदमौपगवम् ॥ **(समिधामाधाने षेण्यण्)**। सामिधेन्यो मन्त्रः ॥ **रथाद्यत्** ।४।३।१२१। रथ्यं चक्रम् ॥ **पत्रपूर्वादञ्** ।४।३।१२२। अश्वरथस्येदं आश्वरथम् ॥ **हलसीराट्ठक्** ।४।३।१२४। हालिकम् । सैरिकम् ॥ **गोत्रचरणाद्वुञ्** ।४।३।१२६। औपगवकम् ॥ **(चरणाद्धर्माम्नाययोरिति वक्तव्यम्)** काठकम् ॥ **संघाङ्कलक्षणेष्वञ्यञिञामण्**[5] ।४।३।१२७। **(घोषग्रहणमपि कर्तव्यम्)** अञ् । बैदः संघोऽङ्को घोषो वा । बैदं लक्षणम् । यञ् । गार्गः । गार्गम् । इञ् । दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः । साक्षात्तु लक्षणम् ॥ इति शैषिकाः ॥

तस्य विकारः ।४।३।१३४। **(अश्मनो विकारे टिलोपो वक्तव्यः)** अश्मनो विकार आश्मः । भास्मनः । मार्त्तिकः[4] ॥ **अवयवे च प्राण्योषधिवृक्षेभ्यः** ।४।३।१३५। चाद्विकारे । मयूरस्य विकारोऽवयवो वा मायूरः । मौर्वम् ।

---

१ दन्त्यमध्योऽयं शाद्वलवत् नतु नड्वलवन्मूर्धन्यमध्यः ॥ २ द्वितीयान्ताद्गच्छतीत्यर्थे प्रत्ययः स्यात् सचेद्गन्ता पन्थाः दूतो वेत्यर्थः ॥ ३ विनोपदेशं ज्ञातमुपज्ञातम् ॥ ४ वुञोऽपवादः ॥ ५ एवंच प्रकृतयस्तिस्रः प्रत्ययार्थविशेषणानि चत्वारीति वैषम्याद्यथासंख्यमपि न प्रवर्तते ॥

काण्डं भस्म वा । पैप्पलम् ॥ **त्रपुजतुनोः षुक्** ।४।३।१३८। आभ्यामण् एतयोः षुक् च । त्रापुषम् । जातुषम् ॥ **ओरञ्** ।४।३।१३९। दैवदारवम् ॥ **अनुदात्तादेश्च** ।४।३।१४०। अञ् । कापित्थम् ॥ **पलाशादिभ्यो वा** ।४।३।१४१। अञ् । पालाशम् । खादिरम् ॥ **शम्या ष्लञ्** ।४।३।१४२। शामीलम् ॥ **मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः** ।४।३।१४३। प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । आश्ममयम् । आश्मनम् । अभक्षेत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥ **नित्यं वृद्धशरादिभ्यः** ।४।३।१४४। आम्रमयम् । शरमयम् ॥ एकाचो नित्यम् । वाङ्मयम् ॥ **गोश्च पुरीषे** ।४।३।१४५। गोमयम् ॥ **एण्या ढञ्** ।४।३।१५९। ऐणेयम् । एणस्य तु ऐणम् ॥ **गोपयसोर्यत्** । ४।३।१६०। गव्यम् । पयस्यम् ॥ **फले लुक्** ।४।३।१६३। विकारावयवप्रत्ययस्य ॥ **लुक् तद्धितलुकि** ।१।२।४९। उपसर्जनस्त्रीप्रत्ययस्य । आमलक्याः फलम् आमलकम् ॥ **प्लक्षादिभ्योऽण्** ।४।३।१६४। विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥ **न्यग्रोधस्य च केवलस्य** ।७।३।५। अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् । **जम्ब्वा वा** ।४।३।१६५। अण् फले । जाम्बवम् । पक्षे ओरञ् । तस्य लुक् ॥ **लुप् च** ।४।३।१६६। जम्ब्वाः फलप्रत्ययस्य लुब्वा स्यात् । लुपि युक्तवत् । जम्बूः ॥ **(फलपाकशुषामुपसंख्यानम्)** । व्रीहयः । मुद्गाः । **(पुष्पमूलेषु बहुलम्)** । मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जातिः । विदार्याः मूलं विदारी । बहुलग्रहणान्नेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥ **हरीतक्यादिभ्यश्च** ।४।३।१६७। फलप्र-

---

१ पलाश, खदिर, शिंशपा, स्यन्दन, पुलाक, करीर, शिरीष, यवास विकङ्कत, इति पलाशादिः ॥ २ कृञः पास इति पासप्रत्यये गुणे रपरे च कार्पासीशब्दो जातिलक्षणङीषन्तः । तस्मादनुदात्तादेश्चेति अञं बाधित्वा बिल्वादित्वादण् ॥ ३ शर, दर्भ, मृग, कुटी, तूण, सोम, बल्वज, इति शरादिः ॥ ४ प्लक्ष, न्यग्रोध, इङ्गुदी, अश्वत्थ, शिग्रु, रुरु, कक्षतु, बृहती, इति प्लक्षादिः ॥ ५ हरीतकी, कोशातकी, नखरजनी, शष्कण्डी, पाडी, दोडी, श्वेतपाकी, अर्जुनपाकी, द्राक्षा, काला, ध्वाङ्क्षा, गर्भीका, कण्टकारिका, पिप्पली, चिञ्चा, शेफालिका, इति हरीतक्यादिः ॥

त्ययस्य लुप्। हरीतक्यादीनां लिङ्गमेव प्रकृतिवत्। हरीतक्याः फलानि हरीतक्यः। इति प्राग्दीव्यतीयाः॥

प्राग्वहतेष्ठक् ।४।४।१। तद्वहतीत्यतः प्राक् ठगधिक्रियते। तदाहेति (**माशब्दादिभ्य[1] उपसंख्यानम्**)। माशब्दः कारि इति य आह स माशब्दिकः॥ (**आहौ प्रभूतादिभ्यः[2]**)। प्रभूतमाह प्राभूतिकः। पार्यासिकः॥ (**पृच्छतौ सुस्नातादिभ्यः[3]**) सुस्नातं पृच्छति सौस्नातिकः। सौखशायनिकः॥ अनुशतिकादिः॥ (**गच्छतौ परदारादिभ्यः[4]**)। पारदारिकः। गौरुतल्पिकः। **तेन दीव्यति खनति जयति जितम्** ।४।४।२। अक्षैर्दीव्यति खनति जयति जितं वा आक्षिकः॥ **संस्कृतम्** ।४।४।३। दध्ना संस्कृतं दाधिकम्। मारिचिकम्॥ **तरति** ।४।४।५। उडुपेन तरति। औडुपिकः॥ **गोपुच्छाट्ठञ्** ।४।४६ गौपुच्छिकः॥ **नौद्व्यचष्ठन्** ।४।४।७। नाविकः। घटिकः॥ **चरति** ।४।४।८। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः। शकटेन चरति शाकटिकः॥ **पर्पादिभ्यष्ठन्[5]** ।४।४।१०। पर्पेण चरति पार्पिकः। येन पीठेन पङ्गवश्चरन्ति स पर्पः। आश्विकः। रथिकः॥ **श्वगणाट्ठञ् च** ।४।४।११। चात्छन्॥ **श्वादेरिञि** ।७।३।८। ऐज् न। श्वाभस्त्रिः (**इकारादाविति वाच्यम्**)। श्वगणेन चरति श्वागणिकः। श्वगणिकः॥ **वेतनादिभ्यो[6] जीवति** ।४।४।१२। वेतनेन जीवति वैतनिकः। धानुष्कः॥ **हरत्युत्सङ्गादिभ्यः** ।४।४।१५। उत्सङ्गेन हरति औत्सङ्गिकः॥ **भस्त्रादिभ्यष्ठन्[7]** ।४।४।१६। भस्त्रया हरति भस्त्रिकः। षित्वाद्

---

१ माशब्द, नित्यशब्द, कार्यशब्द, इति माशब्दादिः॥ २ प्रभूत, प्रर्याप्त, इति प्रभूतादिः॥ ३ सुस्नात, सुखरात्रि, सुखशयन, इति सुस्नातादिः॥ ४ परदार, गुरुतल्प, इति परदारादिः। एते चत्वारोऽप्याकृतिगणाः॥ ५ पर्प, अश्व, अश्वत्थ, रथ, नाल, व्याल, न्यास, पादः पच्च, इति पर्पादिः॥ ६ वेतन, वाहन, अर्धवाहन, धनुष, दण्ड, जाल, वेश, उपवेश, प्रेषण, उपवस्ति, सुख, शय्या, शक्ति, उपनिषत्, उपदेश, स्फिच्, पाद, उपस्थ, उपस्थान, उपहस्त, इति वेतनादिः॥ ७ भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार, इति भस्त्रादिः॥

भस्त्रिकी ॥ **विभाषा विवधात्** ।४।४।१७। ष्ठन् । पक्षे ठक् । विवधेन हरति विवधिकः । एकदेशविकृतत्वाद्वीवधादपि । वैवधिकः । विवधवीवधशब्दौ उभयतोबद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥ **निर्वृत्तेऽक्षद्यूतादिभ्यः** ।४।४।१९। अक्षद्यूतेन निर्वृत्तं आक्षद्यूतिकं वैरम् ॥ **संसृष्टे** ।४।४।२२। दध्ना संसृष्टं दाधिकम् ॥ **लवणाल्लुक्** ।४।४।२४। लवणेन संसृष्टो लवणः सूपः ॥ **मुद्गादण्** ।४।४।२५। मौद्ग ओदनः ॥ **उञ्छति** ।४।४।३२। बदराण्युञ्छति बादरिकः ॥ **रक्षति** ।४।४।३३। समाजं रक्षति सामाजिकः ॥ **शब्ददर्दुरं करोति** ।४।४।३४। शब्दं करोति शाब्दिकः । दार्दुरिकः ॥ **पक्षिमत्स्यमृगान् हन्ति** ।४।४।३५। स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम् । मत्स्यपर्यायेषु मीनस्यैव । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्सिकः । मैनिकः । शाकुनिकः । मार्गिकः । हारिणिकः । सारङ्गिकः ॥ **धर्मं चरति** ।४।४।४१। धार्मिकः ॥ **(अधर्माच्चेति वक्तव्यम्)** । आधर्मिकः ॥ **तदस्य पण्यम्** ।४।४।५१। अपूपाः पण्यमस्य आपूपिकः ॥ **लवणाट्ठञ्** ।४।४।५२। लावणिकः ॥ **शिल्पम्** ।४।४।५५। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥ **प्रहरणम्** ।४।४।५७। असिः प्रहरणमस्य आसिकः । धानुष्कः ॥ **शक्तियष्ट्योरीकक्** ।४।४।५९। शाक्तीकः । याष्टीकः ॥ **अस्ति नास्ति दिष्टं मतिः** ।४।४।६०। अस्ति परलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य दैष्टिकः ॥ **शीलम्** ।४।४।६१। अपूपभक्षणं शीलं यस्य स आपूपिकः ॥ **छत्रादिभ्यो णः** ।४।४।६२। गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्येति छात्रः ॥ **तत्र नियुक्तः** ।४।४।६९। आकरे नियुक्तः आकरिकः ॥ **निकटे वसति** ।४।४।७३। नैकटिको भिक्षुः । इति ठगधिकारः ॥

---

१ अक्षद्यूत, जानुप्रहृत, जङ्घाप्रहृत, जङ्घाप्रहृत, पादस्वेदन, कण्टकमर्दन, गतानुगत, गतागत, यातोपयात, अनुगत, इत्यक्षद्यूतादिः ॥ २ छत्र, शिक्षा, प्ररोह, स्था, बुभुक्षा, चुरा, तितिक्षा, उपस्थान, कृषि, कर्मन्, विश्वधा, तपस्, सत्य, अनृत, विशिखा, विशिका, भक्षा, उदस्थान, पुरोडा, विक्षा, चुक्षा, मन्द्र, इति छत्रादिः ॥

प्राग्घिताद्यत् ।४।४।७५। तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥ **तद्वहति रथयुगप्रासङ्गम्** ।४।४।७६। रथं वहति रथ्यः । युग्यः[1] । प्रासङ्ग्यः ॥ **धुरो यड्ढकौ** ।४।४।७७। धुर्यः धौरेयः ॥ **हलसीराट्ठक्** ।४।४।८१। हलं वहति हालिकः । सैरिकः ॥ **विध्यत्यधनुषा** ।४।४।८३। द्वितीयान्ताद्विध्यतीत्यर्थे यत् नचेत्तत्र धनुष्करणम् । पादौ विध्यन्ति पद्याः[2] शर्कराः ॥ **नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु** ।४।४।९१। नावा तार्यं नाव्यं जलम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम्[3] ॥ **तत्र साधुः** ।४।४।९८। सामसु साधुः सामन्यः । अग्र्यः । कर्मण्यः । शरण्यः ॥ **सभाया यः** ।४।४।१०५। सभ्यः । इति यतोऽवधिः ॥

प्राक् क्रीताच्छः ।५।१।१। तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥ **उगवादिभ्यो यत्**[4] ।५।१।२। प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत् स्याच्छस्यापवादः ॥ **(नाभि नभं च)** । नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् ॥ **(शुनः संप्रसारणं वा च दीर्घत्वम्)** । शुन्यम् । शून्यम् ॥ **(ऊधसो नङ् च)** । ऊधन्यः ॥ **कम्बलाच्च संज्ञायाम्** ।५।१।३। यत् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥ **विभाषा हविरपूपादिभ्यः**[5] ।५।१।४। आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्यास्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥ **तस्मै हितम्** ।५।१।५। वत्सेभ्यो हितो

---

१ युगं रथाङ्गं वहतीत्यर्थः ॥ २ पद्यत्यतदर्थे इति पद्भावः ॥ ३ निम्नोन्नतादिरहितमित्यर्थः । समीकृतमिति यावत् ॥ ४ गो, हविस्, अक्षर, विष, बर्हिस्, अष्टका, स्खदा, युग, मेधा, स्रुच्, नाभि नभं च, शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम्, ऊधसोऽनङ् च, कूप, खद, दर, खर, असुर, अध्वन्, क्षर, वेद, बीज, दीप्त, इति गवादिः ॥ ५ अपूप, तण्डुल, अभ्यूष, अभ्योष, अघोष, अभ्येष, पृथुक, ओदन, सूप, पूप, किण्व, प्रदीप, मुसल, कटक, कर्णवेष्टक, इर्गल, अर्गल, अन्नविकारेभ्यश्च, यूप, स्थूणा, दीप, अश्व, पत्र इत्यपूपादिः ॥

वत्सीयो गोधुक । शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥ **शरीरावयवाद्यत्** ।५।१।६। दन्त्यम् । कण्ठ्यम् । नस्यम् ॥ **अजाविभ्यां थ्यन्** ।५।१।८। अजथ्या यूथिः । अविथ्या ॥ **आत्मन्विश्वजनभोगोत्तरपदात्खः** ।५।१।९। **आत्माध्वानौ खे** ।६।४।१६९। प्रकृत्या स्तः । आत्मने हितं आत्मनीनम् । विश्वजनीनम् । कर्मधारयादेवेष्यते । अन्यत्र विश्वजनीयम् । पञ्चजनादुपसंख्यानम् । पञ्चजनीनम् । 'कुमति च' इति णः । मातृभोगीणः ॥ **(आचार्यादणत्वं च)** आचार्यभोगीनः ॥ इति छयतोः पूर्णोऽवधिः ॥

प्राग्वतेष्ठञ् ।५।१।१८। तेन तुल्यमित्यतः प्राक् ठञधिक्रियते ॥ **आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्** ।५।१।१९। तदर्हतीत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥ **असमासे निष्कादिभ्यः**[1] ।५।१।२०। आर्हादित्यतेत्तने क्रीतमिति यावदनुवर्तते । निष्कादिभ्योऽसमासे ठगार्हीयेष्वर्थेषु । निष्केण क्रीतमिति नैष्किकम् । समासे तु ठञ् ॥ **परिमाणान्तस्यासंज्ञाशाणयोः** ।७।३।१७। उत्तरपदवृद्धिर्ञिदादौ । परमनैष्किकम् ॥ **शताच्च ठन्यतावशते** ।५।१।२१। शत्यम् । शतिकम् । अशते किम् ॥ **संख्याया अतिशदन्तायाः कन्** ।५।१।२२। आर्हीयेर्थे । शतं परिमाणमस्य शतकः सङ्घः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंशत्कः ॥ **वतोरिड्वा** ।५।१।२३। वत्वन्तात्कन इड् वा तावत्कः । तावतिकः ॥ **कंसाट्टिठन्** ।५।१।२५। कंसिकः । अर्धाच्च । अर्धिकः ॥ **अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम्** ।५।१।२८। अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् । अध्यर्धकम् । संज्ञायां तु । पाञ्चकपालिकम् ॥ **तेन**[2] **क्रीतम्** ।५।१।३७। ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । ठक् । नैष्किकम् ॥ **तस्येश्वरः** ।५।१।४२। सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां चेति वृद्धिः । सर्वभूमेरीश्वरः सार्वभौमः पार्थिवः ॥ **तदस्य परिमाणम्**[3] ।५।१।५७। प्रस्थः परिमाणमस्य प्रास्थिको राशिः । स्तोमे-

---

१ निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि, इति निष्कादिः ॥ २ तेनेति तृतीयान्तात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युरित्यर्थः ॥ ३ इह परिमाणशब्देन परिच्छेदकमात्रं गृह्यते नतु सर्वतो मानमेव, उत्तरसूत्रे संख्यायाः परिमाणेन विशेषणात् ॥

डविधिः । पञ्चदशमन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥ **पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्** ।५।१।५९। एते रूढिशब्दा निपात्यन्ते ॥ **तदर्हति** ।५।१।६३। श्वेतच्छत्रमर्हति श्वेतच्छत्रिकः ॥ **दण्डादिभ्यो यत्** ।५।१।६६। एभ्यो यत् । दण्डमर्हति दण्ड्यः । अर्घ्यः । वध्यः ॥ **तेन निर्वृत्तम्** ।५।१।७९। अह्ना निर्वृत्तमाह्निकम् ॥ इति ठञ्ठकोरवधिः ॥

तेन तुल्यं क्रिया चेद्वतिः ।५।१।११५। ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेत् किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥ **तत्र तस्येव** ।५।१।११६। मथुरायामिव मथुरावत्स्रुघ्ने प्राकारः । चैत्रस्येव चैत्रवत् मैत्रस्य गावः ॥ **तस्य भावस्त्वतलौ** ।५।१।११९। प्रकृतिजन्यबोधे प्रकारो भावः ॥ गोर्भावः गोत्वम् । गोता । त्वान्तं क्लीबम् । तलन्तं स्त्रियाम् ॥ **आ च त्वात्** ।५।१।१२०। ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थमिदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥ **पृथ्वादिभ्य इमनिज्वा** ।५।१।१२२। वावचनमणादिसमावेशार्थम् ॥ **र ऋतो हलादेर्लघोः** ।६।४।१६१। इष्ठेमेयस्सु ॥ **टेः** ।६।४।१५५। लोप इष्ठेमेयस्सु । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । पृथोर्भावः । प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ॥ **वर्णदृढादिभ्यः ष्यञ्च** ।५।१।१२३। चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् । द्रढिमा ॥

---

१ दण्ड, मुसल, मधुपर्क, कशा, मेघ, अर्घ, मेधा, सुवर्ण, उदक, वध, युग, गुहा, भाग, इभ, भङ्ग, इति दण्डादिः ॥ २ पृथु, मृदु, महत्, पटु, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, बहुल, खण्ड, दण्ड, चण्ड, अकिंचन, बाल, वत्स, होड, पाक, मन्द, स्वादु, ह्रस्व, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुद्र, अणु, इति पृथ्वादिः ॥ ३ दृढ, वृढ, परिवृढ, भृश, कृश, वक्र, शुक्र, चुक्र, आम्र, कृष्ट, लवण, ताम्र, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, स्थिर, वेर्यातलातमतिर्मनःशारदानाम् । समो मतिमनसोः जवन, इति दृढादिः ॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च ।५।१।१२४। चाद्भावे । जडस्य भावः कर्म वा जाड्यम् । ब्राह्मण्यम् । आकृतिगणोऽयम् ॥ (**चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्**) । चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैवर्ग्यम् । षाड्गुण्यम् । सैन्यम् । सान्निध्यम् । औपम्यम् । त्रैलोक्यमित्यादि ॥ **स्तेनाद्यन्नलोपश्च** ।५।१।१२५। नेति संघातग्रहणम् । स्तेनस्य भावः कर्म वा स्तेयम् ॥ **सख्युर्यः** ।५।१।१२६। सख्यम् ॥ **कपिज्ञात्योर्ढक्** ।५।१।१२७। कापेयम् । ज्ञातेयम् ॥ **पत्यन्तपुरोहितादिभ्यो यक्** ।५।१।१२८। सैनापत्यम् । पौरोहित्यम् । (**राजाऽसे**) । राजन्शब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात् ष्यञ् । आधिराज्यम् ॥ **प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्** ।५।१।१२९। प्राणभृज्जातिः । आश्वम् । वयोवचनम् । कौमारम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् ॥ **हायनान्तयुवा-**

---

१ ब्राह्मण, वाडव, माणव, अर्हतो नुम् च, चोर, धूर्त, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, अक्षेत्रज्ञ, संवादिन्, संवेषिन्, मध्यस्थ, संभाषिन्, बहुभाषिन्, शीर्षघातिन्, विघातिन्, समस्थ, विषमस्थ, परमस्थ, अनीश्वर, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, विश्व, बालिश, आलस, दुःपुरुष, कापुरुष, राजन्, गणपति, अधिपति, गडुल, दायाद, विशस्ति, विशम, विपात, निपात, सर्ववेदादिभ्यः स्वार्थे, चतुर्वेदस्योभयपदवृद्धिश्च, शौटीर, ब्राह्मणादिराकृतिगणः तेन औचित्यमित्यादि सिद्धम् ॥ २ चतुर्वर्ण, चतुराश्रम, सर्वविद्य, त्रिलोक, त्रिस्वर, षड्गुण, सेना, अनन्तर, संनिधि, समीप, उपमा, सुख, तदर्थ, इतिह, मणिक, इति चतुर्वर्णादिः ॥ ३ पुरोहित, राजाऽसे, ग्रामिक, पिण्डिक, सुहित, बाल, मन्द, खण्डिक, दण्डिक, वर्मिक, कर्मिक, धर्मिक, शिलिक, सूतिक, मूलिक, तिलक, अञ्जलिक, अञ्जनिक, ऋषिक, पुत्रिक, अविक, छत्रिक, पर्षिक, पथिक, चर्मिक, प्रतिक, सारथि, आस्तिक, सूचिक, संरक्षक, सूचक, नास्तिक, अजानिक, शाकर, नागर, चूडिक, इति पुरोहितादिः ॥ ४ उद्गातृ, उन्नेतृ, प्रतिहर्तृ, प्रशास्तृ, होतृ, पोतृ, हर्तृ, रथगणक, पत्तिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, सुभग, मन्त्र, इत्युद्गात्रादिः ॥ ५ युवन्, स्थविर, होतृ, यजमान, पुरुषासे, भ्रातृ, कुतुक, श्रमण, कटुक, कमण्डलु, कुस्त्री, सुस्त्री, दुःस्त्री, सुहृदय, दुर्हृदय, सुहृद्, दुर्हृद्, सुभ्रातृ, दुर्भ्रातृ, वृषल, परिव्राजक, सब्रह्मचारिन्, अनृशंस, हृदयासे, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, श्रोत्रियस्य यलोपश्च, इति युवादिः ॥

दिभ्योऽण् ।५।१।१३०। द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् । **(श्रोत्रियस्य यलोपश्च)** श्रौत्रम् कुशलनिपुणचपलपिशुनकुतूहलक्षेत्रज्ञाः युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥ **इगन्ताच्च लघुपूर्वात्** ।५।१।१३१। शुचेर्भावः कर्म वा शौचम् । मौनम् ॥ **योपधाद्गुरूपोत्तमाद्वुञ्** ।५।१।१३२। रामणीयकम् । आभिधानीयकम् ॥ **(सहायाद्वा)** साहाय्यम् । साहायकम् ॥ **द्वन्द्वमनोज्ञादिभ्यश्च**[1] ।५।१।१३३। शैष्योपाध्यायिका । मानोज्ञकम् ॥ इति नञ्स्नञोरवधिः ॥

धान्यानां भवने क्षेत्रे खञ् ।५।२।१। मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥ **व्रीहिशाल्योर्ढक्** ।५।२।२। व्रैहेयम् । शालेयम् ॥ **यवयवकषष्टिकाद्यत्** ।५।२।३। यव्यम् । यवक्यम् । षष्टिक्यम् ॥ **विभाषा तिलमाषोमाभङ्गाणुभ्यः** ।५।२।४। यत् । पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥ **तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति** ।५।२।७। सर्वादेः पथ्याद्यन्तात् द्वितीयान्तात्खः । सर्वपथान् व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः। सर्वपात्रीणः ॥ **हैयङ्गवीनं संज्ञायाम्** ।५।२।२३। नवनीते निपातोऽयम् ॥ **तस्य पाकमूले पील्वादिकर्णादिभ्यः**[2][3] **कुणब्जाहचौ** ।५।२।२४। पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् ॥ **पक्षात्तिः** ।५।२।२५। मूले इत्यनुवर्तते । पक्षस्य मूलं पक्षतिः ॥ **तेन वित्तश्चुञ्चुप्चणपौ** ।५।२।२६। यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टः । तेन चस्य नेत्वम् । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥ **वेः शालच्छंकटचौ** ।५।२।२८। क्रिया-

---

१ मनोज्ञ, प्रियरूप, अभिरूप, कल्याण, मेधाविन्, आढ्य, कुलपुत्र, छान्दस, छात्र, श्रोत्रिय, चोर, धूर्त, विश्वदेव, युवन्, कुपुत्र, ग्रामपुत्र, ग्रामकुलाल, ग्रामषण्ड, ग्रामकुमार, सकुमार, बहुल, अवश्यपुत्र, अमुष्यपुत्र, अमुष्यकुल, सारपत्र, शतपत्र, इति मनोज्ञादिः ॥ २ पीलु, कर्कन्धू, शमी, करीर, कुवलय, बदर, अश्वत्थ, खदिर, इति पील्वादिः ॥ ३ कर्ण, अक्षि, नख, मुख, केश, पाद, गुल्फ, भ्रू, शृङ्ग, दन्त, ओष्ठ, पृष्ठ, इति कर्णादिः ॥

विशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशंकटम् ॥ **संप्रोदश्च कटच् ।५।२।२९।** संकटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ **(अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्)** । अलाबूनां रजोऽलाबूकटम् । तिलकटम् ॥ **(गोष्ठजादयः स्थानादिषु पशुनामभ्यः)** गवां स्थानं गोष्ठम् ॥ **संघाते कटच्)** अवीनां संघातोऽविकटः ॥ **(विस्तारे पटच्)** । अविपटः ॥ **(द्वित्वे गोयुगच्)** । द्वावुष्ट्रौ उष्ट्रगोयुगम् । **(षट्त्वे षड्गवच्)** । अश्वषड्गवम् । **(स्नेहे तैलच्)** तिलतैलम् । सर्षपतैलम् ॥ **अवात्कुटारच्च ।५।२।३०।** चात्कटच् । अवकुटारः । अवकटः ॥ **नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ।५।२।३१।** अवादित्येव । नतं नमनम् । नासिकाया नतम् अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगान्नासिकावटीटा । पुरुषोऽवटीटः ॥ **उपाधिभ्यां त्यकन्नासन्नारूढयोः ।५।२।३४।** पर्वतस्यासन्नं स्थलं उपत्यका । आरूढं स्थलमधित्यका ॥ **कर्मणि घटो ठच् ।५।२।३५।** कर्मणि घटते कर्मठः ॥ **तदस्य संजातं तारकादिभ्य[१] इतच् ।५।२।३६।** तारकाः संजाता अस्य तारकितं नभः । पण्डितः । आकृतिगणोऽयम् ॥ **प्रमाणे द्वयसज्दघ्नञ्मात्रचः ।५।२। ३७।** ऊरू प्रमाणमस्य ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् । 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम । ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः' ॥ ४ ॥ **पुरुषहस्तिभ्यामण् च ।५।२।**

---

१ तारका, पुष्प, कर्णक, मञ्जरी, ऋजीष, क्षण, सूत्र, मूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, विचार, कुण्डल, कण्टक, मुसल, कुसुम, कुतूहल, स्तबक, किसलय, पल्लव, खण्ड, वेग, निद्रा, मुद्रा, बुभुक्षा, धेनुष्या, पिपासा, श्रद्धा, अभ्र, पुलक, अङ्गारक, वर्णक, द्रोह, दोह, सुख, दुःख, उत्कण्ठा, भर, व्याधि, वर्मन्, व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, चन्द्रक, अन्धक, गर्व, मुकुर, हर्ष, उत्कर्ष, रण, कुवलय, गर्ध, क्षुध्, सीमन्त, ज्वर, गर, रोग, रोमाञ्च, पण्डा, कज्जल, तृष, कोरक, कल्लोल, स्थपुट, फल, कञ्चुक, शृङ्गार, अङ्कुर, शैवल, बकुल, श्वभ्र, अराल, कलङ्क, कर्दम, कन्दल, मूर्च्छा, अङ्गार, हस्तक, प्रस्तिक, प्रतिबिम्ब, विघ्नतन्त्र, प्रत्यय, दीक्षा, गर्ज, गर्भादप्राणिनि । इति तारकादिराकृतिगणः ॥

३८। पुरुषः प्रमाणमस्य पौरुषम्। पुरुषद्वयसम्। हास्तिनम्। हास्तिद्वयसम्॥ **यत्तदेतेभ्यः परिमाणे वतुप्** ।५।२।३९। यत्परिमाणमस्य यावान्। तावान्। एतावान्॥ **किमिदंभ्यां वो घः** ।५।२।४०। आभ्यां वतुब्वस्य च घः॥ **इदंकिमोरीश्की** ।६।३।९०। दृग्दृशवतुषु। कियान्॥ **किमः संख्यापरिमाणे डति च** ।५।२।४१। चाद्वतुप् तस्य च घः। का संख्या येषां ते कति। कियन्तः॥ **संख्याया अवयवे तयप्** ।५।२।४२। पञ्च अवयवा अस्य पञ्चतयम्॥ **द्वित्रिभ्यां तयस्यायज्वा** ।५।२।४३। द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥ **उभादुदात्तो नित्यम्** ।५।२।४४। उभशब्दात्तयपोऽयच् स्यात् सचाद्युदात्तः। उभयम्॥ **तदस्मिन्नधिकमिति दशान्ताड्डः** ।५।२।४५। एकादश अधिका अस्मिन्नेकादशम्। (**शतसहस्रयोरेवेष्यते**)। नेह एकादशाऽधिका अस्यां विंशत्याम्। 'प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते'। नेह एकादश माषा अधिका अस्मिन् सुवर्णशते॥ **शदन्तविंशतेश्च** ।५।२।४६। डः स्यादुक्तेऽर्थे। त्रिंशदधिका अस्मिन् त्रिंशम्। विंशम्॥ **तस्य पूरणे डट्** ।५।२।४८। संख्याया इत्येव। एकादशानां[1] पूरण एकादशः॥ **नान्तादसंख्यादेर्मट्** ।५।२।४९। डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम्। विंशः। असंख्यादेः किम्। एकादशः॥ **षट्कतिकतिपयचतुरां थुक्** ।५।२।५१। डटि। षण्णां पूरणः षष्ठः। कतिथः कतिपयशब्दस्यासंख्यात्वेऽपि अतएव ज्ञापकात् डट्। कतिपयथः। चतुर्थः॥ (**चतुरश्छयतावाद्यक्षरलोपश्च**)। तुरीयः। तुर्यः॥ **बहुपूगगणसङ्घस्य तिथुक्** ।५।२।५२। डटि। बहुतिथः॥ **वतोरिथुक्** ।५।२।५३। डटि। यावतिथः॥ **द्वेस्तीयः** ।५।२।५४। डटोऽपवादः। द्वयोः पूरणो द्वितीयः॥ **त्रेः संप्रसारणं च** ।५।२।५५। तृतीयः। इह हल इति दीर्घो न। द्वितीय-

---

१ प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य' इति परिभाषया तदादिनियमः स्यात्तं वारयितुमन्तग्रहणम्॥ २ उद्भूतावयवभेदः समुच्चयः प्रकृत्यर्थः। अवयव इह प्रत्ययार्थः। यस्मात्संख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः॥

तृतीयेति निर्देशात् ॥ **विंशत्यादिभ्यस्तमडन्यतरस्याम्** ।५।२।५६। डटः । विंशतितमः । विंशः । एकविंशतितमः । एकविंशः ॥ **नित्यं शतादिमासार्धमाससंवत्सराच्च** ।५।२।५७। शतस्य पूरणः शततमः । मासादेरत एव ज्ञापकात् डट् । मासतमः ॥ **षष्ठ्यादेश्चासंख्यादेः** ।५।२।५८। षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥ **मतौ च्छः सूक्तसाम्नोः** ।५।२।५९। मत्वर्थे । अच्छावाकशब्दोऽस्त्यस्मिन्नच्छावाकीयं सूक्तम् । वारवन्तीयं साम ॥ **श्रोत्रियंश्छन्दोऽधीते** ।५।२।८४। श्रोत्रियः । वेत्यनुवृत्तेः छान्दसः ॥ **श्राद्धमनेन भुक्तमिनिठनौ** ।५।२।८५। श्राद्धी । श्राद्धिकः । **पूर्वादिनिः** ।५।२।८६। पूर्वं कृतमनेन पूर्वी ॥ **सपूर्वाच्च** ।५।२।८७। कृतपूर्वी ॥ **इष्टादिभ्यश्च**[1] ।५।२।८८। इष्टमनेनेष्टी । अधीती ॥ **अनुपद्यन्वेष्टा** ।५।२।९०। अनुपदमन्वेष्टा अनुपदी गवाम् ॥ **साक्षाद्द्रष्टरि संज्ञायाम्** ।५।२।९१। साक्षाद्द्रष्टा साक्षी॥**तदस्यास्त्यस्मिन्निति मतुप्** ।५।२।९४। गावोऽस्यास्मिन्वा सन्ति गोमान्॥ **तसौ मत्वर्थे** ।१।४।१९। तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । संप्रसारणम् । विदुष्मान् । गुणवचनेभ्यो मतुपो लुगिष्टः । शुक्लो गुणोऽस्यास्ति शुक्लः पटः । कृष्णः ॥ **प्राणिस्थादातो लजन्यतरस्याम्** ।५।२।९६। चूडालः । चूडावान् । प्राणिस्थात्किम् । शिखावान्दीपः । प्राण्यङ्गादेव । नेह । मेधावान् ॥ **सिध्मादिभ्यश्च**[2] ।५।

---

१ इष्ट, पूर्त, उपासादित, निगदित, परिगदित, परिवादित, निकथित, निषादित, निपठित, संकलित, परिकलित, संरक्षित, परिरक्षित, अर्चित, गणित, अवकीर्ण, आयुक्त, गृहीत, आम्नात, श्रुत, अधीत, अवधान, आसेवित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, अनुयुक्त, अनुगणित, अनुपठित, व्याकुलित, इतीष्टादिः ॥ २ सिध्म, गडु, मणि, नाभि, बीज, वीणा, कृष्ण, निष्पाव, पांसु, पार्श्व, पर्शु, हनु, सक्तु, मास, पार्ष्णिधमन्योर्दीर्घश्च, वातदन्तबलललाटानामूङ् च, जटा, घटा, कटा, कालाः क्षेपे, पर्ण, उदक, प्रज्ञा, सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, पुष्क, पृथु, मृदु, मञ्ज, मण्ड, पत्र, चटु, कपि, गण्ड, ग्रन्थि, श्री, कुश, धारा, वर्ष्मन्, श्लेष्मन्, पक्ष्मन्, पेश, निष्पाद्, कण्ड, क्षुद्रजन्तूपतापयोश्च, इति सिध्मादिः ॥

२।९७। लज्वा । सिध्मलः । सिध्मवान् । (वातदन्तबलललाटानामूङ् च) वातूलः । दन्तूलः । बलूलः । ललाटूलः ॥ **वत्सांसाभ्यां कामबले ।५।२।९८।** लज्वा यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥ **फेनादिलच्च ।५।२।९९।** चाल्लच् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥ **लोमादि[1]पामादि[2]पिच्छादि[3]भ्यः शनेलचः ।५।२।१००।** लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः । **(अङ्गात्कल्याणे)** अङ्गना ॥ **(लक्ष्म्या अच्च)** । लक्ष्मणः ॥ **(पिच्छादिभ्य इलच्)** । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥ **प्रज्ञाश्रद्धार्चाभ्यो णः ।५।२।१०१।** प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः । वृत्तेश्च । वार्तः ॥ **तपःसहस्राभ्यां विनीनी ।५।२।१०२।** विनीन्योरिकारो नकारपरित्राणार्थः ॥ तपस्वी । सहस्री ॥ **अण् च ।५।२।१०३।** तापसः । साहस्रः ॥ **(ज्योत्स्नादि[4]भ्य उपसंख्यानम्)** ज्यौत्स्नः । तामिस्रः[5] ॥ **सिकताशर्कराभ्यां च ।५।२।१०४।** सैकतो घटः । शार्करः ॥ **देशे लुबिलचौ च ।५।२।१०५।** चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकता । सिकतिलः । सैकतः । सिकतावान् । एवं । शर्करेत्यादि ॥ **दन्त उन्नत उरच् ।५।२।१०६।** उन्नता दन्ता अस्य दन्तुरः ॥ **ऊषसुषिमुष्कमधो रः ।५।२।१०७।** ऊषरः । सुषिरः । मुष्कोऽण्डः । मुष्करः । मधुरः । **(रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्)** । खरः । मुखरः । कुञ्जो हस्ति-

---

१ लोमन्, रोमन्, बभ्रु, अरि, गिरि, कर्क, कपि, सुति, तरु, इति लोमादिः ॥ २ पामन्, वामन्, वेगन्, हेमन्, श्लेष्मन्, कद्रु, वलि, सामन्, ऊष्मन्, कृमि, अङ्गात्कल्याणे, शाकीपलालीदद्रूणां ह्रस्वत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः । लक्ष्म्या अच्च, इति पामादिः ॥ ३ पिच्छा, उरस्, ध्रुवक, ध्रुवक, जटा, घटा, कालाः क्षेपे, पर्ण, उदक, पङ्क, प्रज्ञा, इति पिच्छादिः । ४ ज्योत्स्ना, तमिस्रा, कुण्डल, कुतप, विसर्प, विपादिका, इति ज्योत्स्नादिः ॥ ५ तमःसमूहस्तमिस्रं 'ज्योत्स्नातमिस्रा–' इति निपातनान्मत्वर्थीयो रः । तत्र ह्यवयवभूतानि तमांसि विद्यन्ते । तदस्मिन्नस्तीति विग्रहे रान्तादण् ॥

हनुः । कुञ्जरः ॥ **(नगपांसुपाण्डुभ्यश्च)** । नगरम् । पांसुरः । पाण्डुरः ॥ **(कच्छ्वा ह्रस्वत्वं च)** कच्छुरः ॥ **द्युद्रुभ्यां मः** ।५।२।१०८। द्युमः[1] । द्रुमः ॥ **केशाद्वोऽन्यतरस्याम्** ।५।२।१०९। प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणं इनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् । 'अन्येभ्योऽपि दृश्यते' मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ **(अर्णसो लोपश्च)** अर्णवः ॥ **गाण्ड्यजगात्संज्ञायाम्** ।५।२।११०। ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डीवम् । गाण्डिवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥ **काण्डाण्डादीरन्नीरचौ** ।५।२।१११। काण्डीरः । आण्डीरः॥ **रजःकृष्यासुतिपरिषदो वलच्** ।५।२।११२। रजस्वला स्त्री । कृषीवलः । वल इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदिति पाठान्तरम् । पर्षद्वलः । 'अन्येभ्योऽपि दृश्यते' । भ्रातृवलः । पुत्रवलः । शत्रुवलः ॥ **दन्तशिखात्संज्ञायाम्** ।५।२।११३। दन्तावलो हस्ती । शिखावलः केकी ॥ **अत इनिठनौ** ।५।२।११५। दण्डी । दण्डिकः ॥ **व्रीह्यादिभ्यश्च**[2] ।५।२।११६। व्रीही । व्रीहिकः ॥ **तुन्दादिभ्य इलच्च** ।५।२।११७। चादिनिठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर पिचण्ड यव व्रीहि इति तुन्दादिः ॥ **रूपादाहतप्रशंसयोर्यप्** ।५।२।१२०। आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । 'अन्येभ्योऽपि दृश्यते' । हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥ **अस्मायामेधास्रजो विनिः** ।५।२।१२१। यशस्वी । यशस्वान्[3] । मायावी । मायावान् । व्रीह्यादिपाठान्मायी । मायिकः । स्रग्वी ॥ **(शृङ्गवृन्दाभ्यामारकन्)** शृङ्गारकः । वृन्दारकः ॥ **(फलबर्हाभ्यामिनच्)** । फलिनः । बर्हिणः ॥ **(हृदयाच्चालुरन्यतरस्याम्)** हृदयालुः । हृदयी । हृदयिकः । हृदयवान् **(शीतोष्णतृप्रेभ्यस्तदसहने)** शीतं न सहते

---

१ द्यौरस्यास्ति 'दिवउत्' इत्युत्वम् ॥ २ व्रीहि, माया, शाला, शिखा, माला, मेखला, केका, अष्टका, पताका, चर्मन्, कर्मन्, दंष्ट्रा, संज्ञा, वडवा, कुमारी, नौ, वीणा, बलाका, यवखद, शीर्षामय, इति व्रीह्यादिः ॥ ३ नित्यग्रहणात्पूर्वमसंबद्धमप्यन्तरस्यांग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव । तसौ मत्वर्थ इति सूत्रे यशस्वानिति भाष्योदाहरणात् ॥

शीतालुः । उष्णालुः । तृप्रः पुरोडाशस्तन्न सहते तृप्रालुः ॥ **(तप्पर्वमरुद्भ्याम्)** पर्वतः । मरुत्तः ॥ **ऊर्णाया युस्** ।५।२।१२३। ऊर्णायुः ॥ **वाचो ग्मिनिः** ।५।२।१२४। वाग्मी ॥ **आलजाटचौ बहुभाषिणि** ।५।२।१२५। **(कुत्सित इति वक्तव्यम्)** । कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु वदति तत्र वाग्मीत्येव ॥ **स्वामिन्नैश्वर्ये** ।५।२।१२६। ऐश्वर्यवाचकात् स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥ **अर्शआदिभ्योऽच्** ।[१]५।२।१२७। अर्शांसि अस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥ **वातातीसाराभ्यां कुक् च** ।५।२।१२९। चादिनिः । वातकी । अतिसारकी ॥ **(पिशाचाच्च)** । पिशाचकी ॥ **हस्ताज्जातौ** ।५।२।१३३। हस्ती ॥ **वर्णाद्ब्रह्मचारिणि** ।५।२।१३४। वर्णी । **कंशंभ्यां बभयुस्तितुतयसः**।५।२।१३८।कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्यसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । एवं शंब इत्यादि ॥ **तुन्दिबलिवटेर्भः** ।५।२।१३९। तुंदिभः । बलिभः । वटिभः ॥ **अहंशुभमोर्युस्** ।५।२।१४०। अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥ इति मत्वर्थीयाः ॥

प्राग् दिशो विभक्तिः ।५।३।१। दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः । अथ स्वार्थिकाः ॥ **किंसर्वनामबहुभ्योऽद्व्यादिभ्यः** ।५।३।२। किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥ **पञ्चम्यास्तसिल्** ।५।३।७। पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा ॥ **कु तिहोः** ।७।२।१०४। किमः कुस्तादौ हादौ च विभक्तौ । कुतः । कस्मात् ॥ **इदम इश्** ।५।३।३। प्राग्दिशीये । इतः ॥ **अन्** ।६।४।१६७। एतदः प्राग्दिशीये । अनेकाल्त्वात्सर्वादेशः । अतः । अमुतः । यतः । ततः । बहुतः । [२]द्व्यादेस्तु द्वाभ्याम् ॥ **पर्यभिभ्यां च** ।५।३।९। तसिल् । परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥**सप्तम्यास्त्रल्**

---

१ अर्शस्, उरस्, तुन्द, चतुर, पलित, जटा, घटा, घाटा, अघ, कर्दम, अम्ल, लवण स्वाङ्गाद्धीनात्, वर्णात्, अर्शआदिराकृतिगणः ॥ २ द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम् ॥

।५।३।१०। कुत्र । यत्र । तत्र । बहुत्र ॥ **इदमो हः** ।५।३।११। त्रलोऽपवादः । इह ॥ **किमोत्**[1] ।५।३।१२। वा स्यात् ॥ **क्वाति** ।७।२।१०५। किमः । क्व । कुत्र ॥ **इतराभ्योऽपि दृश्यन्ते** ।५।३।१४। पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥ **सर्वैकान्यकिंयत्तदः काले दा** ।५।३।१५। सप्तम्यन्तेभ्य एभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् ॥ **सर्वस्य सोऽन्यतरस्यां दि** ।५।३।६। दादौ प्राग्दिशीये सर्वस्य सो वा । सर्वस्मिन् काले । सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा । काले किम् । सर्वत्र देशे ॥ **इदमोर्हिल्** ।५।३।१६। सप्तम्यन्तात् ॥ **एतेतौ रथोः** ।५।३।४। इदम एत इत् एतौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥ **अधुना** ।५।३।१७। इदमो निपातोऽयम् ॥ **दानीं च** ।५।३।१८। इदमो दानीं प्रत्ययः काले । इदानीम् ॥ **तदो दा च** ।५।३।१९। तदा । तदानीम् ॥ **अनद्यतने र्हिलन्यतरस्याम्** ।५।३।२०। कर्हि । कदा । यर्हि । यदा । तर्हि । तदा ॥ **एतदोन्** ।५।३।२१। एत इत् एतौ स्तो रेफादौ थकारादौ च प्राग्दिशीये । एतस्मिन्काले एतर्हि ॥ **सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः** ।५।३।२२। एते निपात्यन्ते ॥ (**द्युश्चोभयाद्वक्तव्यः**) उभयेद्युः ॥ **प्रकारवचने थाल्** ।५।३।२३। प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् । तेन प्रकारेण तथा ।[3] यथा ॥ **इदमस्थमुः** ।५।३।२४। थालोऽपवादः ॥ (**एतदोऽपि वाच्यः**) अनेन एतेन वा प्रकारेण इत्थम् ॥ **किमश्च**[2] ।५।३।२५। केन प्रकारेण कथम् । इति प्राग्दिशीयाः ॥

दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ।५।

---

१ 'न विभक्तौ तु स्माः' इति निषेधोऽत्र न प्रवर्तते । थमोरुकारेण मकारपरित्राणार्थेनानित्यत्वज्ञापनात् ॥ २ योगविभागः 'थाहेतौ च च्छन्दसि–' इत्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो माभूदिति ॥ ३ यथासंख्यमत्र नेष्यते ॥

।३।२७। सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिः ॥ **पूर्वाधरावराणामसिपुरधवश्चैषाम्** ।५।३।३९। एभ्योऽस्तात्यर्थेऽसिस्तद्योगे चैषां पुर अध अव इत्यादेशाः स्युः ॥ **अस्ताति च** ।५।३।४०। पूर्वादीनां पुरादयः स्युः । पूर्वस्याम् पूर्वस्याः पूर्वा वा दिक् । पुरः पुरस्तात् । अधः । अधस्तात् । अवः ॥ **विभाषाऽवरस्य** ।५।३।४१। अस्तातौ अव्वा स्यात् । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति चेति ज्ञापकादसिरस्तातिं न बाधते ॥ **दक्षिणोत्तराभ्यामतसुच्** ।५।३।२८। अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥ **विभाषा परावराभ्याम्** ।५।३।२९। परतः । परस्तात् । अवरतः । अवरस्तात् ॥ **अञ्चेर्लुक्** ।५।३।३०। अञ्चत्यन्ता-द्दिक्शब्दादस्तातेर्लुक् स्यात् । प्राक् । उदक् ॥ **उपर्युपरिष्टात्** ।५।३।३१। निपातावेतौ ॥ **पश्चात्** ।५।३।३२। तथा ॥ **उत्तराधरदक्षिणादातिः** ।५।३।३४। उत्तरात् । अधरात् । दक्षिणात् ॥ **एनबन्यतरस्यामदूरेऽपञ्चम्याः** ।५।३।३५। उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये । पञ्चम्यन्तात्तु न । उत्तरेण । अधरेण । दक्षिणेन । पक्षे । यथास्वं प्रत्ययाः । इह केचिद्दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् ॥ **दक्षिणादाच्** ।५।३।३६। अस्तातेर्विषये । दक्षिणावसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥ **आहि च दूरे** ।५।३।३७। चादाच् । दक्षिणाहि । दक्षिणा ॥ **उत्तराच्च** ।५।३।३८। उत्तराहि । उत्तरा ॥ **संख्याया विधार्थे धा** ।५।३।४२। क्रियाप्रकारे वर्तमानात् संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा[१] ॥ **एकाद्धो ध्यमुञन्यतरस्याम्** ।५।३।४४। ऐकध्यम् । एकधा ॥ **द्वित्र्योश्च धमुञ्** ।५।३।४५। आभ्यां धा इत्यस्य धमुञ् वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ **एधाच्च** ।५।३।४६। द्वेधा । त्रेधा ॥ **याप्ये पाशप्** ।५।३।४७। कुत्सितो

---

१ इह हि विधायामिति वक्तव्ये अर्थग्रहणस्य, प्रयोजनं विधाशब्दो यत्रार्थे प्रसिद्धस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव । स च क्रियाविषयक एव गृह्यते अभिधानस्वभावात्त-दाह—क्रियाप्रकारे वर्तमानादिति ।

भिषग्भिषक्पाशः ॥ **(तीयादीकक् स्वार्थे वा वाच्यः)** । द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ॥ **(न विद्यायाः)** । द्वितीया विद्येत्येव ॥ **एकादाकिनिच्चासहाये** ।५।३।५२। चात्कन्लुकौ । एकः । एकाकी । एककः ॥ **भूतपूर्वे चरट्** ।५।३।५३। आढ्यो भूतपूर्वः । आढ्यचरः ॥ **षष्ठ्या रूप्य च** । ५।३।५४। षष्ठ्यन्ताद्भूतपूर्वे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः । कृष्णचरः ॥ **अतिशायने[१] तमबिष्ठनौ** ।५।३।५५। अतिशयविशिष्टार्थे एतौ स्तः । अयमेषामतिशयेनाढ्य आढ्यतमः । लघुतमो लघिष्ठः ॥ **तिङश्च** । ५।३।५६। तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥ **तरप्तमपौ घः** ।१।१।२२। **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** ।५।४।११। किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किन्तमाम् । प्राह्णेतमाम् । प्रगेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥ **द्विवचनविभज्योपपदे तरबीयसुनौ** ।५।३।५७। द्वयोरेकस्याऽतिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुतरो लघीयान् । उदीच्याः प्राच्येभ्यः पटवः । पटुतराः । पटीयांसः ॥ **अजादी गुणवचनादेव** ।५।३।५८। इष्ठन्नीयसुनौ । नेह । पाचकतरः । पाचकतमः ॥ **प्रशस्यस्य श्रः** ।५।३।६०। इष्ठेयसोः परतः ॥ **प्रकृत्यैकाच्** ।६।४।६३। इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥ **ज्य च** ।५।३।६१। प्रशस्यस्य ज्यादेश इष्ठेयसोः । ज्येष्ठः ॥ **ज्यादादीयसः** । ६।४।१६०। 'आदेः परस्य' । ज्यायान्[२] ॥ **वृद्धस्य च** ५।३।६२। ज्यादेशं अजाद्योः । ज्येष्ठः । ज्यायान् ॥ **अन्तिकबाढयोर्नेदसाधौ** ।५।३।६३। अजाद्योरिष्ठेयसोः । नेदिष्ठः नेदीयान् । साधिष्ठः । साधीयान् ॥ **स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः** ।६।४।१५६। एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयसुन् । ह्रस्वक्षि-

---

१ अवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते तदा तरबीयसुनावपवादौ वक्ष्येते । तथाच परिशेषाद्बहूनां मध्ये यदा एकस्य निर्धारणं सोऽस्य विषय इति भावः ॥ २ ज्यादुत्तरस्येयसुन आकारादेशः स्यादित्यर्थः ॥

प्रक्षुद्राणां पृथ्वादित्वाद्ब्रसिमा । क्षेपिमा । क्षोदिमा ॥ **प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणांप्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः ।६।४।१५७।** प्रियादीनां प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ॥ **बहोर्लोपो भू च बहोः ।६।४।१५८।** बहोः परयोरिष्ठेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥ **इष्ठस्य यिट् च ।६।४।१५९।** बहोः परस्य इष्ठस्य लोपो यिडागमश्च । भूयिष्ठः ॥ **विन्मतोर्लुक् ।५।३।६५।** इष्ठेयसोः परतः । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥ **प्रशंसायां[१] रूपप् ।५।३।६६।** सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः । पटुरूपः । पचतिरूपम् ॥ **ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।५।३।६७।** ईषदूनो विद्वान् विद्वत्कल्पः । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥ **विभाषा सुपो बहुच् पुरस्तात्तु ।५।३।६८।** ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥ **प्रागिवात्कः ।५।३।७०।** इवे प्रतिकृताविव्यतः प्राक्काधिकारः ॥ **अव्ययसर्वनाम्नामकच् प्राक् टेः ।५।३।७१।** कापवादः । तिङश्चेत्यनुवर्तते ॥ **कस्य च दः ।५।३।७२।** कान्तादव्ययस्य दादेशोऽकच्च ॥ **अज्ञाते ।५।३।७३।** कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । पचतकि । धकित् ॥ **कुत्सिते ।५।३।७४।** कुत्सितोऽश्वोऽश्वकः । **अल्पे ।५।३।८५।** अल्पं तैलं तैलकम् । ह्रस्वो वृक्षो वृक्षकः ॥ **(अस्मिन्प्रकरणे हलादौ प्रत्यये द्वितीयादचः परस्य लोपो वा वाच्यः)** । देवदत्तकः । देवकः । **(लोपः पूर्वपदस्य च)** । दत्तकः । **(विनापि प्रत्ययं पूर्वोत्तरपदयोर्लोपो वा वाच्यः)** । सत्यभामा । भामा । सत्या ॥ **कुटीशमीशुण्डाभ्यो रः ।५।३।८८।** ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः ॥ **कुत्वा डुपच् ।५।३।७९।** ह्रस्वा कुतूः । कुतुपः । 'कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान्' ॥ **कासूगो-**

---

१ प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा न तु स्तुतिः । चौररूपोऽयं यदक्ष्णोरप्यञ्जनं हरति । गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते ॥

णीभ्यां ष्टरच् ।५।३।९०। आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी ॥ **वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे** ।५।३।९१। वत्सतरः।उक्षतरः । अश्वतरः । ऋषभतरः ॥ **किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्** ।५।३।९२। अनयोः कतरो वैष्णवः । यतरः । ततरः ॥ **वा बहूनां जातिपरिप्रश्ने डतमच्** ।५।३।९३। जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् ॥ **एकाच्च प्राचाम्** ।५।३।९४। डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः । इति प्रागिवीयाः ॥

इवे प्रतिकृतौ ।५।३।९६। कन्स्यात् । अश्व इव प्रतिकृतिरश्वकः ॥ **शाखादिभ्यो यः** ।५।३।१०३। शाखेव शाख्यः । मुख्यः । जघन्यः । अग्र्यः । शरण्यः ॥ **कुशाग्राच्छः** ।५।३।१०५। कुशाग्रीयः ॥ **तत्प्रकृतवचने मयट्** ।५।४।२१। प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावे अधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नं अन्नमयम् । अपूपमयम् । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥ **संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्** ।५।४।१७। अभ्यावृत्तिर्जन्म[3] क्रियाजन्मगणनवृत्तेः संख्यायाः स्वार्थे कृत्वसुच् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥ **द्वित्रिचतुर्भ्यः सुच्** ।५।४।१८। कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिर्भुङ्क्ते । 'रात्सस्य' । चतुर्भुङ्क्ते ॥ **एकस्य सकृच्च** ।५।४।१९। सकृदादेशः चात्सुच् । सकृद्भुङ्क्ते ॥ **देवतान्तात्तादर्थ्ये यत्** ।५।४।२४। तदर्थ एव तादर्थ्यम् । अत एव स्वार्थे ष्यञ् । अग्निदेवतायै इदमग्निदैवत्यम् । पितृदैवत्यम् ॥ **पादार्घाभ्यां च** ।५।४।२५। पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ **अतिथेर्ञ्यः** ।५।४।२६। अतिथये इदमातिथ्यम् ॥ (**नवस्य नू आदेशस्त्नप्तनप्खाश्च वक्तव्याः**) । स्वार्थे ।

---

१ तनुत्वं न्यूनता साच प्रवृत्तिनिमित्तस्य प्रत्यासत्तेः । क्वचित्तु तत्सहचरितधर्मान्तराणाम् ॥ २ शाखा, मुख, श्रृङ्ग, जघन, मेघ, अभ्र, चरण, स्कन्ध, उरस्, शिरस्, अग्र, शरण, इति शाखादिः ॥ ३ अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्यते तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्वः इति स्यादतोऽत्र विवक्षितार्थमाह—अभ्यावृत्तिर्जन्मेति ॥

नूत्नम् । नूतनम् । नवीनम् ॥ **(भागरूपनामभ्यो धेयः)** । भागधेयम् । रूपधेयम् । नामधेयम् ॥ **(आग्नीध्रसाधारणादञ्)** । आग्नीध्रम् । साधारणम् ॥ **देवात्तल्** ।५।४।२७। देव एव देवता ॥ **अवेः कः** ।५।४।२८। अविरेव अविकः ॥ **[१]यावादिभ्यः कन्** ।५।४।२९। याव एव यावकः । मणिकः । **(सर्वप्रातिपदिकेभ्यः स्वार्थे कन्)** । बहुतरकम् ॥ **मृदस्तिकन्** ।५।४।३९। मृदेव मृत्तिका ॥ **सस्नौ प्रशंसायाम्** ।५।४।४०। रूपपोऽपवादः । प्रशस्ता मृन्मृत्सा । मृत्स्ना ॥ **[२]प्रज्ञादिभ्यश्च** ।५।४।३८। अण् स्यात् । प्रज्ञ एव प्राज्ञः । दैवतः । बान्धवः ॥ **पूगाञ्ञ्योऽग्रामणीपूर्वात्** ।५।४।११२। स्वार्थे । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । लौहितध्वज्यः ॥ **ञ्यादयस्तद्राजाः** ५।३।११९। तद्राजस्येति लुक् । लोहितध्वजाः । व्रातेति ञ्यञ् । कापोतपाक्यः । कपोतपाकाः । कौंजायना इत्यादि ॥ **बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्** ।५।४।४२। बहूनि ददाति । बहुशः । अल्पशः । बह्वल्पार्थान्मङ्गलामङ्गलवचनम् । नेह । बहु ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥ **संख्यैकवचनाच्च वीप्सायाम्** ।५।४।४३। द्वौ द्वौ ददाति द्विशः । माषं माषं ददाति माषशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥ **प्रतियोगे पञ्चम्यास्तसिः** ।५।४।४४। प्रतिना कर्मप्रवचनीयेन योगे

---

१ याव, मणि, अस्थि, तालु, जानु, सान्द्र, पीत, स्तम्ब, ऋतावुष्णशीते, पशौ लूनविपाते, अण्डनिपुणे, पुत्रकृत्रिमे, स्नानवेदसमाप्तौ, शून्यरिक्ते, दानकुत्सिते, तनुसत्रे, ईयसश्च, ज्ञात, अज्ञात, कुमारी, क्रीडनकानि च, इति यावादिः ॥ २ प्रज्ञ, वणिज्, उष्णिज्, उशिज्, प्रत्यक्ष, विद्वस्, विद्वन्, षोडन्, विद्या, मनस्, श्रोत्रशरीरे, जुहत्, कृष्णमृगे, चिकीर्षत्, चोर, शत्रु, योध, चक्षुस्, वसु, एनस्, मरुत्, क्रुञ्च, सत्वत्, दशार्ह, वयस्, व्याकृत, असुर, रक्षस्, पिशाच, अशनि, कार्षापण, देवता, बन्धु, इति प्रज्ञादिः ॥

या पञ्चमी विहिता तदन्तात्तसिः । प्रद्युम्नः कृष्णतः प्रति ॥ (**आद्यादिभ्यस्तसेरुपसंख्यानम्**)। आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥ **कृभ्वस्तियोगे संपद्यकर्तरि च्विः** ।५।४।५०। (**अभूततद्भाव इति वक्तव्यम्**)। विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥ **अस्य च्वौ** ।७।४।३२। इत् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गी स्यात् ॥ (**अव्ययस्य च्वावीत्वं नेति वाच्यम्**)। दोषाभूतमहः । दिवाभूता रात्रिः ॥ **क्यच्व्योश्च** ।६।४।१५२। हलः परस्यापत्यस्य लोपः क्ये च्वौ च परतः । गार्गीभवति ॥ **च्वौ च** ।७।४।२६। दीर्घः । शुचीभवति । पटू स्यात् ॥ **अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च** ।५।४।५१। चात् च्विः । अरूकरोति । उन्मनीकरोति । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विरजीकरोति ॥ **विभाषा साति कार्त्स्न्ये** ।५।४।५२। च्वेर्विषये सातिर्वा स्यात्साकल्ये । 'सात्पदाद्योः' । कृत्स्नं शस्त्रमग्निः संपद्यते । अग्निसाद्भवति । अग्नीभवति । कार्त्स्न्ये किम् । एकदेशेन शुक्लीभवति पटः ॥ **अभिविधौ संपदा च** ।५।४।५३। संपदा कृभ्वस्तिभिश्च योगे सातिर्वा व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । सम्पदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलीभवति लवणम् ॥ **तदधीनवचने** ।५।४।५४। सातिः कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजाधीनमित्यर्थः ॥ **देये त्रा च** ।५।४।५५। तदधीने देये त्रा स्यात्सातिश्च क्रादियोगे । विप्राधीनं देयं करोति विप्रत्राकरोति । विप्रत्रासंपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥ **देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्** ।५।४।५६। एभ्यो द्वितीयान्तेभ्यः

---

१ 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति कर्मप्रवचनीयसंज्ञायां प्रतिनिधिप्रतिदाने च यस्मादिति पञ्चमी ॥ २ आदि, मध्य, अन्त, पृष्ठ, पार्श्व, इत्यादिराकृतिगणः ॥ ३ पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्सन्नियोगशिष्टत्वार्थः ॥

सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा[1] । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥ **अव्यक्तानुकरणाद्‌द्व्यजवरार्धादनितौ डाच् ।५।४।५७।** द्व्यजवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड् डाच् कृभ्वस्तिभिर्योगे ॥ **(डाचि बहुलं द्वे भवतः)** । डाचि विवक्षिते द्वित्वम् ॥ **(नित्यमाम्रेडिते डाचीति वक्तव्यम्)** डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तपयोः पः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । जनितौ किम् । पटिति करोति ॥ **कृञो द्वितीयतृतीयशंबबीजात्कृषौ ।५।४।५८।** द्वितीयादिभ्यो डाच् कृञो योग एव । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शंबाकरोति । बीजाकरोति ॥ **संख्यायाश्च गुणान्तायाः ।५।४।५९।** द्विगुणाकरोति क्षेत्रम् ॥ **समयाच्च यापनायाम् ।५।४।६०।** कृषाविति निवृत्तम् । समयाकरोति । कालं यापयतीत्यर्थः ॥ **सपत्रनिष्पत्रादतिव्यथने ।५।४।६१।** सपत्रा[2]करोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्राकरोति । सपुङ्खस्य शरस्याऽपरपार्श्वे निर्गमनान्निष्पत्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् ॥ **निष्कुलान्निष्को[3]षणे ।५।४।६२।** निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥ **सुखप्रियादानुलोम्ये ।५।४।६३।** सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥ **दुःखात्प्रातिलोम्ये ।५।४।६४।** दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥ **शूलात्पाके ।५।४।६५।** शूलाकरोति । शूलेन पचतीत्यर्थः ॥ **सत्या[4]दशपथे ।५।४।६६।** सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति

---

१ देवान् वन्दे देवत्रावन्दे देवेषु रमे देवत्रारमे इत्यर्थोऽत्र पर्यवसन्नः । एवं मनुष्यान् गच्छति मनुष्यत्रागच्छतीत्यादि बोध्यम् ॥ २ लक्ष्ये शराः पतन्ति अनेनेति पत्रं शराणां पुङ्खगतो बर्हः ॥ ३ निष्कोषणमन्तरवयवानां बहिर्निष्कासनम् । ४ सत्सु साधुः सत्यम् । 'तत्र साधुः' इति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनात् यः ॥

तथ्यं करोतीत्यर्थः। शपथे तु सत्यं करोति विप्रः॥ **मद्रात्परिवापणे** ।५।४।६७। मद्रशब्दो मङ्गलार्थः। परिवापणं मुण्डनम्। मद्राकरोति कुमारम्। माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः॥ **(भद्राच्चेति वक्तव्यम्)**। भद्राकरोति। अर्थः प्राग्वत्। परिवापणे किम्। मद्रं करोति भद्रं करोति॥ **इति तद्धितप्रक्रिया**॥

सर्वस्य द्वे।८।१।१। इत्यधिकृत्य[1]॥ **परेर्वर्जने** ।८।१।५। परेर्वर्जनेऽर्थे द्वे स्तः। परिपरिवङ्गेभ्यो वृष्टो देवः॥ **उपर्यध्यधसः सामीप्ये** ।८।१।७। उपर्युपरि ग्रामम्। ग्रामस्योपरिष्टात्समीपदेशे इत्यर्थः। अध्यधिसुखम्। सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः। अधोधोलोकम्। लोकस्याधस्तात्समीपदेशे इत्यर्थः॥ **वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु** ।८।१।८। सुन्दरसुन्दर वृथा ते सौन्दर्यम्। देव देव वन्द्योसि। दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि। धानुष्क धानुष्क वृथा ते धनुः। चोर चोर घातयिष्यामि त्वाम्॥ **एकं बहुव्रीहिवत्** ।८।१।९। द्विरुक्त एकशब्दो बहुव्रीहिवत्। तेन सुब्लोपपुंवद्भावौ[2]। एकैकमक्षरम्। इह द्वयोरपि सुपोर्लुकि सति बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप्। तच्च एकवचनमेव। एकैकयाहुत्या॥ **आबाधे च** ।८।१।१०। पीडायां द्वे स्तो बहुव्रीहिवच्च। गतगतः। गतगता॥ **प्रकारे गुणवचनस्य** ।८।१।१२। सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत्। पटुपट्वी। पटुपटुः। पटुसदृश ईषत्पटुरिति यावत्॥ **(आनुपूर्व्ये द्वे वाच्ये)**। मूलेमूले स्थूलः॥ **(संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः)**। सर्प २ बुध्यस्व २। सर्प ३ बुध्यस्व ३। **(कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये। समासवच्च बहुलम्)**। बहुलग्रहणादन्यपरयोर्न समासवत्। इतरशब्दस्य तु नित्यम्। **(असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः**। अन्योन्यं विप्रा नमन्ति। अन्योन्यौ। अन्योन्येन कृतम्। अन्योन्यस्मै दत्तमित्यादि। **(स्त्रीनपुंसकयोरु-**

---

१ नित्यवीप्सयोः इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चेति भावः॥

२ यद्यप्येतौ बहुव्रीहौ विशिष्य न विहितौ तथापि तत्र दृष्टावित्येवातिदिश्येते इति भावः॥

त्तरपदस्थाया विभक्तेराम्भावो वाच्यः)। अन्योन्याम्। अन्योन्यम्। परस्पराम्। परस्परम्। इतरेतराम् इतरेतरं वा इमे ब्राह्मण्यौ कुले वा भोजयतः॥ दलद्वये टाबभावः क्लीबे चाड्विरहः स्वमोः। समासे सोरलुक् चेति सिद्धं बाहुलकात्त्रयम्। अन्योन्यमित्यादौ दलद्वये टाप्। अदूडतरेत्यदड् च प्राप्तः। 'अन्योन्यसंसक्तमहस्त्रियामम्'। अन्योन्याश्रयः। परस्पराक्षिसादृश्यम्। अदृष्टपरस्परैरित्यादौ सोर्लुक् च प्राप्तः। सर्वं बाहुलकात्समाधेयम्॥ **इति द्विरुक्तप्रक्रिया**॥

स्त्रियाम् ।४।१।३। अधिकारोऽयम्। समर्थानामिति यावत्॥ **अजाद्यतष्टाप्**[1] ।४।१।४। अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात्। अजादिभिः स्त्रीत्वस्य विशेषणान्नेह। पञ्चाजी। अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम्। अतः। खट्वा। अजा। एडका। अश्वा। [2]चटका। मूषिका। बाला। वत्सा। होढा। मन्दा। विलाता॥ **(संभस्त्राजिनशणपिण्डेभ्यः फलात्)**। संफला। भस्त्रफला इत्यादि॥ **(सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्)**। सत्पुष्पा। प्राक्पुष्पा। प्रत्यक्पुष्पा॥ **(शूद्रा चामहत्पूर्वा जातिः)**। पुंयोगे तु शूद्री। अमहत्पूर्वा किम्। महाशूद्री। क्रुञ्चा। उष्णिहा। देवविशा। ज्येष्ठा। कनिष्ठा। मध्यमेति पुंयोगेपि। कोकिला जातावपि॥ **(मूलान्नञः)**। अमूला॥ **उगितश्च** ।४।१।६। ङीप्। भवन्ती। पचन्ती॥ **वनो र च** ।४।१।७। वन्नतात्तदन्ताच्च ङीप् स्याद्रश्चान्तादेशः। सुत्वानमतिक्रान्ता अतिसुत्वरी। अतिधीवरी। शर्वरी॥ **(वनो न हश इति वक्तव्यम्)**। अवावा ब्राह्मणी। राजयुध्वा॥

---

१ अज, एडक, अश्व, चटक, मूषिक, बाल, वत्स, होड, पाक, मन्द विलात, पूर्वापहाण, उत्तरापहाण, क्रुञ्चा, उष्णिहा, देवविशा, ज्येष्ठा, मध्यमेति पुंयोगेऽपि, कोकिला जातावपि। दंष्ट्रा, एतेऽजादयः। आकृतिगणोऽयम्॥ २ क्षिपकादित्वादित्वं नेति शब्देन्दुशेखरे॥ ३ 'आभीरी तु महाशूद्री जातिपुंयोगयोः समा' इत्यमरः। इह अमहत्पूर्वेति व्यर्थं महाशूद्रशब्दो हि समुदित एवाभीरत्वजातौ वर्तते। तत्रावयवस्यानर्थकतया शूद्रशब्दार्थसमवेतस्त्रीत्वाभावेन टापः प्रसक्त्यभावादिति तत्वबोधिनी॥

(बहुव्रीहौ वा) । बहुधीवा । बहुधीवरी ॥ **पादोऽन्यतरस्याम्** ।४।१।८। द्विपदी । द्विपात् ॥ **टाबृचि** ।४।१।९। द्विपदा ऋक् । एकपदा ॥ **मनः** ।४।१।११। मन्नन्तान्न ङीप् । सीमानौ ॥ **अनो बहुव्रीहेः** ।४।१।१२। अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥ **डाबुभाभ्यामन्यतरस्याम्** ।४।१।१३। सूत्रद्वयोपात्ताभ्यां डाब् वा । सीमा । सीमे । सीमानौ । दामे दामानौ ॥ **अन उपधालोपिनोऽन्यतरस्याम्** ।४।१।२८। अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् । पक्षे डाबनिषेधौ । बहुराज्ञी । बहुराज्ञ्यौ । बहुराजा । बहुराजानौ ॥ **प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः** ।७।३।४४। प्रत्ययस्थात्ककारात्पूर्वस्याकारस्येकारः स्यादापि परे स आप्सुपः परो न चेत् । सर्विका । कारिका । अतः किम् । नौका । प्रत्ययस्थात्किम् । शक्नोतीति शका । असुपः किम् । बहुपरिव्राजका नगरी ॥ **(मामकनरकयोरुपसंख्यानम्)**[1] । मामिका[2] । नरिका ॥ **(त्यक्त्यपोश्च)** दाक्षिणात्यिका[3] । इहत्यिका ॥ **न यासयोः** ।७।३।४५। यत्तदोरस्येन्न । यका । सका । यकाम् । तकाम् ॥ **(त्यकनश्च निषेधः)** उपत्यका । अधित्यका ॥ **आशिषि वुनश्च न)** । जीवका । भवका ॥ **(उत्तरपदलोपे न)** । देवदत्तिका । देवका । **(क्षिपकादीनां च)** । क्षिपका । ध्रुवका । चटका । कन्यका ॥ **(तारका ज्योतिषि)** । **(वर्णका तान्तवे)** । **(वर्तका शकुनौ प्राचाम्)** । **(अष्टका पितृदेवत्ये)** । **(सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम्)** । एषां वा अकारो भवतीत्यर्थः । सूतिका सूतकेत्यादि ॥ **उदीचामातः स्थाने यकपूर्वायाः** ।७।३।४६। यकपूर्वस्य स्त्रीप्रत्ययस्यातः स्थाने योऽत् तस्य कात्पूर्वस्येद्वापि परे । क्रेण इति ह्रस्वः । आर्यका । चटकका । चटकिका । आतः किम् । सांकाश्ये भवा सांकाश्यिका । यकेति किम् । अश्विका । स्त्रीप्रत्ययस्य किम् । शुभंयिका ॥ **अभाषितपुंस्काच्च** ।७।३।४८। एतस्माद्विहित-

---

१ ककारस्य प्रत्ययस्थत्वाभावादप्राप्ते वचनम् । २ 'केवलमामक' इत्यादिना संज्ञाछन्दसोरेवेति नियमान्न ङीप् । ३ दक्षिणस्यामदूरे दक्षिणा 'दक्षिणादाच्' दक्षिणा भवेति विग्रहे 'दक्षिणापश्चात्पुरसस्त्यक्' 'किति च' इत्यादिवृद्धिः ।

स्यातः स्थानेऽत इद्वा । गङ्गका । गङ्गिका ॥ **आदाचार्याणाम्** ।७।३।४९। पूर्वविषये । गङ्गाका ॥ **अनुपसर्जनात्** ।४।१।१४। अधिकारोऽयं यूनस्तिरित्यभिव्याप्य[1] ॥ **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** ।४।१।१५। अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं ततो ङीप् । कुरुचरी । उपसर्जनत्वान्नेह । बहुकुरुचरा । नदट् । नदी । देवट् । देवी । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ (**नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्**) । स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यंकरणी । तरुणी । तलुनी ॥ **यञश्च** ।४।१।१६। यञन्तात्प्रातिपदिकाद् ङीप् । अकारलोपे कृते ॥ **हलस्तद्धितस्य** ।६।४।१५०। हल उत्तरस्योपधाभूततद्धितयस्य लोप इति । गार्गी ॥ **प्राचां ष्फ तद्धितः** ।४।१।१७। यञन्तात्ष्फो वा ॥ **षः प्रत्ययस्य** ।१।३।६। प्रत्ययादिः ष इत्स्यात् । आयनेयीनीत्यायनादेशः । षित्वसामर्थ्यात्षिद्गौरेति ङीप् । गार्ग्यायणी ॥ **वयसि प्रथमे** ।४।१।२०। प्रथमवयोवाचिनोऽदन्तान्न ङीप् । कुमारी ॥ (**वयस्यचरम इति वाच्यम्**) वधूटी । चिरंटी ॥ **द्विगोः** ।४।१।२१। अदन्तात् द्विगोर्ङीप् । त्रिलोकी । अजादित्वात् त्रिफला । त्र्यनीका सेना ॥ **अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि** ।४।१।२२। अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्न ङीप् तद्धितलुकि । पञ्चभिरश्वैः क्रीता पञ्चाश्वा ॥ (**आर्हीयष्ठक्**) । अध्यर्धेति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणात्तु द्व्याढकी[2] । तद्धितलुकि किम् । समाहारे पञ्चाश्वी ॥ **काण्डान्तात्क्षेत्रे** ।४।१।२३। क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे[3] प्रमाणमस्या द्विकाण्डा क्षेत्रभक्तिः । मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक् । क्षेत्रे किम् । द्विकाण्डी रज्जुः ॥ **पुरु-**

---

१ अतएव बहुयुवा शालेत्यत्र यूनस्तिरिति न प्रवर्तत इति प्राञ्चः । २ गोत्रप्रत्ययान्तस्य जातित्वेऽपि योपधत्वादत्र 'जातेः' इति ङीप् न भवति । तथाचाद्युदात्तमेवेदं पदम् । ३ षोडशहस्तप्रमाणो दण्डः काण्डम् । ४ पुरुषशब्दो यद्यपि लोके जातिवचनस्तथापि द्वौ पुरुषौ प्रमाणमस्या इति वाक्ये प्रमाणशब्दसामानाधिकरण्यात्प्रमाणे वर्तते ।

षात्प्रमाणेऽन्यतरस्याम् ।४।१।२४। प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीब्वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्या द्विपुरुषी । द्विपुरुषा वा परिखा ॥ **ऊधसोऽनङ्** ।५।४।१३१ । ऊधोन्तस्य बहुव्रीहेरनङ् स्त्रियाम् ॥ **बहुव्रीहेरूधसो ङीष्** ।४।१।२५। ऊधोन्ताद्बहुव्रीहेः । कुण्डोध्नी । स्त्रियां किम् । कुण्डोधो धैनुकम् ॥ **दामहायनान्ताच्च** ।४।१।२७। संख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् । द्विदाम्नी । द्विहायनी बाला ॥ (**त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम्**) । वयोवाचकहायनस्य ङीप् णत्वं चेष्यते । त्रिहायणी । चतुर्हायणी । वयसोन्यत्र । त्रिहायना । चतुर्हायना शाला ॥ **अन्तर्वत्पतिवतोर्नुक्** ।४।१।३२। नान्तत्वान्ङीप् । अन्तर्वत्नी । पतिवत्नी । गर्भभर्तृसंयोग एवेष्यते । अन्यत्र तु[1] अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥ **पत्युर्नो यज्ञसंयोगे** ।४।१।३३। वसिष्ठस्य पत्नी ॥ **विभाषा सपूर्वस्य** ।४।१।३४। पतिशब्दान्तस्य नो वा गृहपतिः । दृढपत्नी । दृढपतिः ॥ **नित्यं[2] सपत्न्यादिषु** ।४।१।३५। सपत्नी । एकपत्नी । वीरपत्नी ॥ **पूतक्रतोरै च** ।४।१।३६। पूतक्रतोः स्त्री पूतक्रतायी ॥ **वृषाकप्यग्निकुसितकुसिदानामुदात्तः** ।४।१।३७। एषामुदात्त ऐ आदेशो ङीप् च । वृषाकपेः स्त्री वृषाकपायी । अग्नायी । कुसितायी । कुसिदायी ॥ **मनोरौ वा** ।४।१।३८। मनुशब्दस्यौकारादेशः स्यादुदात्तैकारश्च वा ङीप् च । मनायी । मनावी । मनुः ॥ **वर्णादनुदात्तात्तोपधात्तो नः** ।४।१।३९। वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्ताद्वा ङीप् तस्य नः । एता । एनी । रोहिता । रोहिणी ॥ **षिद्गौरादिभ्यश्च** ।४।१।४१। ङीष् । नर्तकी । गौरी । अनडुही । अनड्वाही ॥ (**पिप्पल्यादयश्च**) । आकृतिगणोऽयम् ॥ (**मत्स्यस्य ङ्याम्**) । यलोपः । मत्सी ॥ **जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽयोविकारमैथुनेच्छाकेशवेशेषु** ।४।१।४२। एकादशभ्यः क्रमाद्वृत्त्यादिष्वर्थेषु ङीष् । जानपदी वृत्तिश्चेत्[3] । अन्या-

---

१ अन्तर्वती पतिवतीति प्राचोक्तं प्रत्युदाहरणमयुक्तमिति भावः । २ आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । ३ वर्ततेऽनयेति वृत्तिर्जीविका ।

जानपदी । अञन्तत्वात् ङीपि आद्युदात्तः । कुण्डी[1] अमत्रं चेत् । कुण्डान्या । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलान्या । भाजी श्राणा चेत् । भाजान्या । 'यवागूरुष्णिका श्राणा विलेपी तरला च सा' इत्यमरः । नागी स्थूला चेत् । नागान्या । काली वर्णश्चेत् । कालान्या । नीली अनाच्छादनं चेत् । नीलान्या । नील्यां रक्ता शाटीत्यर्थः । कुशी[2] अयोविकारश्चेत् । कुशान्या । कामुकी मैथुनेच्छावती चेत् । कामुकान्या । कबरी केशानां सन्निवेशविशेषश्चेत् । कबरान्या ॥ **शोणात्प्राचाम्** ।४।१।४३। शोणी । शोणा ॥ **वोतो गुणवचनात्** ।४।१।४४। उदन्ताद्गुणवाचिनो वा ङीष् । मृद्वी । मृदुः । उतः किम् । शितिः । गुणेति किम् । आखुः ॥ (**खरुसंयोगोपधान्न**) । खरुः । पाण्डुः ॥ **बह्वादिभ्यश्च** ।४।१।४५। वा ङीष् । बह्वी । बहुः ॥ (**कृदिकारादक्तिनः**) । रात्री । रात्रिः ॥ (**सर्वतोऽक्तिन्नर्थादित्येके**) । शकटी । शकटिः ॥ **पुंयोगादाख्यायाम्** ।४।१।४८। या पुमाख्या पुंयोगात्स्त्रियां वर्तते ततो ङीष् । गोपस्य स्त्री गोपी ॥ (**पालकान्तान्न**) गोपालिका । अश्वपालिका । सूर्याद्देवतायां चाप् । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती मानुषीयम् ॥ **इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्** ।४।१।४९। ङीष् च । इन्द्राणी ॥ (**हिमारण्ययोर्महत्त्वे**) । महद्धिमं हिमानी ॥ (**यवाद्दोषे**) । दुष्टो यवो यवानी ॥ (**यवनाल्लिप्याम्**) । यवनानां लिपिर्यवनानी ॥ (**मातुलोपाध्याययोरानुग्वा**) । मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥ (**आचार्यादणत्वं च**) । आचार्यानी ॥ (**अर्यक्षत्रियाभ्यां वा स्वार्थे**) । अर्याणी । अर्या । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी ॥ **क्रीतात्करणपूर्वात्** ।४।१।५०। क्रीतान्तादकारान्तात्करणादेर्ङीष् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥ **बहुव्रीहेश्चान्तोदात्तात्** ।४।१।५२। क्तान्ता-

---

१ 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः । २ फाल इति प्रसिद्धः । ३ सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥ १ ॥ ४ जात्यन्तरमेवानेनाभिधीयते । अयमेवास्य दोषो यस्मात्स्वीययवत्वजातेरभावेऽपि तदाकारानुकृतिः ।

न्ङीष् ऊरुभिन्नी ॥ **अस्वाङ्गपूर्वपदाद्वा** ।४।१।५३। पूर्वेण नित्ये प्राप्ते विकल्पोयम् । सुरापीती[1] । सुरापीता । **स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्** ।४।१।५४। असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताद्वा ङीष् । अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु । सुगुल्फा । अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथा युतम् ॥ १ ॥ सुस्वेदा । द्रवत्वात् । सुज्ञाना । अमूर्तत्वात् । सुमुखा शाला । अप्राणिस्थत्वात् । सुशोफा । विकारजत्वात् । सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥ **नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च** । ४।१।५५। वा ङीष् । तुङ्गनासिकी । तुङ्गनासिका ॥ **(पुच्छाच्च)** सुपुच्छी । सुपुच्छा ॥ **(कबरमणिविषशरेभ्यो नित्यम्)** । कबरपुच्छी ॥ **(उपमानात्पक्षाच्च पुच्छाच्च)** उलूकपक्षी शाला । उलूकपुच्छी सेना ॥ **न क्रोडादिबह्वचः** ।४।१।५६। क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । आकृतिगणोयम् । सुजघना ॥ **सहनञ्विद्यमानपूर्वाच्च** ।४।१।५७। न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥ **नखमुखात्संज्ञायाम्** ।४।१।५८। ङीष् न । शूर्पणखा[2] । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या ॥ **वाहः** ।४।१।६१। वाहन्तान् ङीष् । दित्यौही ॥ **सख्यशिश्वीति भाषायाम्** ।४।१।६२। सखी । अशिश्वी ॥ **जातेरस्त्रीविषयादयोपधात्** ।४।१।६३। जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततो ङीष् ॥ आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥ १ ॥ घटी । वृषली । औपगवी । कठी । जातेः किम् । मुण्डा । अस्त्रीविषयात्किम् । बलाका । अयोपधात्किम् । क्षत्रिया ॥ **(योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः)** हयी । गवयी । मुकयी ।

---

१ पीता सुरा यया सा । जातिकाल इति सूत्रवार्तिकाभ्यां निष्ठाया अन्तोदात्तत्वपरनिपातौ । २ पूर्वपदात्संज्ञायामिति णत्वम् । यदा तु शूर्पवन्नखानि यस्या इति योगमात्रं विवक्ष्यते न तु संज्ञा ततोऽसंज्ञात्वान्न ङीष्निषेधो न वा णत्वं, तेन राक्षस्यपि योगवृत्त्या शूर्पनखीति भवतीत्याहुः ॥

मानुषी । मत्सी ॥ **पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च** ।४।१।६४। पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् । ओदनापाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढाः ॥ **इतो मनुष्यजातेः** ।४।१।६५। ङीष् । दाक्षी[1] ॥ **ऊङुतः** ।४।१।६६। उकारान्तादयोपधान्मनुष्यजातिवाचिन ऊङ् । कुरूः ॥ **पङ्गोश्च** ।४।१।६८। पङ्गूः ॥ **(श्वशुरस्योकाराकारलोपश्च)** चादूङ् पुंयोगलक्षणङीषोऽपवादः । श्वश्रूः ॥ **ऊरूत्तरपदादौपम्ये**[2] ।४।१।६९। उपमानवाचिपूर्वपदमूरूत्तरपदं यत्तस्मादूङ् । करभोरूः ॥ **संहितशफलक्षणवामादेश्च** ।४।१।७०। संहितोरूः ॥ **(सहितसहाभ्यां च)** सहितोरूः । सहोरूः ॥ **शार्ङ्गरवाद्यञो ङीन्** ।४।१।६३। शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् । शार्ङ्गरवी[3] । बैदी ॥ **(नृनरयोर्वृद्धिश्च)** नारी ॥ **यङश्चाप्** ।४।१।७४। यङन्ताच्चाप् । आम्बष्ठ्या । कारीषगन्ध्या ॥ **(षाद्यञश्चाब्वाच्यः)** पौतिमाष्या ॥ **आवट्याच्च** ।४।१।७५। अस्माच्चाप् । यञश्चेति ङीपोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥ **यूनस्तिः** ।४।१।७७। युवन्शब्दात्तिः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां बहुयुवा । युवतीति तु यौतेः शत्रन्तान्ङीपि बोध्यम् । इति स्त्रीप्रत्ययाः ॥

अथ वैदिकप्रक्रिया ।

षष्ठीयुक्तश्छन्दसि वा ।४।१।९। पतिशब्दो घिसंज्ञः । क्षेत्रस्य पतिना वयम् । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । तेन सर्वे विधयश्छन्दसि वैकल्पिकाः । बहुलं छन्दसीत्यादिरस्यैव प्रपञ्चः ॥ **अयस्मयादीनि च्छन्दसि** ।१।४।२०। साधूनि । भपदसंज्ञाधिकाराद्यथायोगं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ **(उभयसंज्ञान्यपीति वक्तव्यमिति)** ससुष्टुभा सऋक्वता गणेन । पदत्वात्कुत्वम् । भत्वाजश्त्वाभावः । नैनं हिन्वन्त्यपि वाजिनेषु । अत्र पदत्वाजश्त्वं भत्वा-

---

१ अत इञ् । गोत्रलक्षणा जातिः । अदन्तत्वाभावादप्राप्तो ङीष् विधीयते । २ उपमीयतेऽनयेत्युपमा तस्या भाव औपम्यम् । ३ शृङ्गशब्दादपत्येऽण् आदिवृद्धिः । 'ओर्गुणः' 'टिड्ढाणञ्' इति ङीपं बाधित्वा परत्वाज्जातेरिति ङीषि प्राप्ते ङीन् विधीयते । तेनाद्युदात्तः ।

त्कुत्वाभावः । 'ते प्राग्धातोः' ॥ **छन्दसि परेऽपि** ।१।४।८१। **व्यवहिताश्च** । १।४।८२। हरिभ्यां याह्योक आ । आमन्द्रैरिन्द्र हरिभिर्याहि ॥ **तृतीया चहोश्छन्दसि** ।२।३।३। जुहोतेः कर्मणि तृतीया स्याद् द्वितीया च । यवाग्वाग्निहोत्रं जुहोति ॥ **मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्** ।३।२।७१। **(श्वेतवहादीनां डस् पदस्येति वक्तव्यम्)**। यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । सक्थशासौ । पुरो दाश्यते दीयते पुरोडाः ॥ **अवे यजः** ।३।२।७२। अवयाः । अवयाजौ । अवयाजः ॥ **अवयाः श्वेतवाः पुरोडाश्च** ।८।२।६७। एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥ **लिङर्थे लेट्** ।३।४।७। **सिब्बहुलं लेटि** ।३।१।३४। **इतश्च लोपः परस्मैपदेषु** । ३।४।९७। लेटस्तिङां वा ॥ **लेटोऽडाटौ** ।३।४।९४। स्तो वा तौ च पितौ ॥ **(सिब्बहुलं णिद्वक्तव्यः)** । वृद्धिः । प्रणआयूंषि तारिषत् । सुपेशसस्करतिजोषिषद्धि । आसाविषदर्शसानाय । सिप इलोपस्य चाभावे । पताति विद्युत् । प्रियः सूर्ये प्रियो अग्ना भवाति ॥ **स उत्तमस्य** । ३।४।९८। लेट उत्तमस्य वा लोपः । करवावः । करवाव । टेरेत्वम् ॥ **आत ऐ** ।३। ।४।९५। लेट आकारस्य । सुतेभिः सुप्रयसामादयैते । आतामित्याकारस्य ऐ ॥ **वैतोऽन्यत्र** ।३।४।९६। लेट एकारस्य ऐः स्याद्वा आत ऐ इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यन्ते । अन्यत्र किम् । सुप्रयसामादयैते ॥ **उपसंवादाशङ्कयोश्च** ।३।४।८४। पणबन्धे आशङ्कायां च लेट् । अहमेव पशूनामीशै । नेज्जिह्मायन्तो नरकं पताम ॥ **व्यत्ययो बहुलम्** ।३।१।८५। विकरणानां छन्दसि । आण्डाशुष्णस्य भेदति । भिनत्तीति प्राप्ते । जरसा मरते पतिः । म्रियत इति प्राप्ते । इन्द्रो वस्तेनेषतु । नयतेर्लोट् । शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेमवृत्रम् । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः सिप शप् चेति त्रयो विकरणाः ॥ "सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन" ॥ १ ॥ धुरि दक्षिणायाः । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय

तक्षति । तक्षन्ती प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते । मधुन इति प्राप्ते । नरः पुरुषः । 'अधा स वीरैर्दशभिर्वियूयाः । वियूयादिति प्राप्ते । कालः कालवाची प्रत्ययः श्वोऽग्नीनाधास्यमानेन । लुटो विषये लट् । तमसो गा अनुक्षत् । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः । मित्रावयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययस्तु अन्नादायः अण्विषये अच् । यङो यशब्दादारभ्य लिङ्याशिष्यङिति ङकारेण प्रत्याहारः॥ तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥ **छन्दस्युभयथा** ।३।४।११७। धात्वधिकारोक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञा स्यात् ॥ वर्धन्तु त्वा सुष्टुतयः । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः ॥ विशृण्विरे । सार्वधातुकत्वात् श्नुः श्नभावश्च । हुश्नुवोरिति यण् ॥ **तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः** ।३।४।९। से वक्षेरायः । सेन् । तावामेषे असे । शरदो जीवसे धाः । असे । नित्याद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे । अध्यै । अध्यैन् । जठरं पृणध्यै । पक्षे । आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै । शध्यै । राधसः सहमादयध्यै । शध्यैन् । वायवे पिबध्यै । तवै । दातवाउ । तवेङ् । सूतवे । तवेन् । कर्तवे ॥ **प्रयै रोहिष्यै अव्यथिष्यै** ।३।४।१०। एते निपात्यन्ते । प्रयातुं रोढुं अव्यथितुमित्यर्थः ॥ **दृशे विख्ये च** ।३।४।११। निपातौ । द्रष्टुं विख्यातुमित्यर्थः ॥ **कृत्यार्थे तवैकेन्केन्यत्वनः** ।३।४।१४। धातोरेते स्युः ॥ तवै । अन्वेतवै । केन् । अवगाहे । केन्ये । दिदृक्षेण्यः । त्वन् । कर्त्वम् ॥ **सृपितृदोः कसुन्** ।३।४।१७। तुमर्थे । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जतृभ्य आतृदः ॥ **प्रकृत्यान्तःपादमव्यपरे** ।६।१।११५। ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यान्न तु वकारपरे अति । उपप्रयन्तो अध्वरम् । सुजाते अश्वसूनृते । अन्तःपादं किम् । एतास एतेर्चन्ति । अव्यपरे किम् । ते वदन् ॥ **अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च** ।६।१।११६। एषु व्यपरेऽप्यति एङ्प्रकृत्या । वसुभिर्नो अव्यात् । मित्र महो अवद्यात् । मा शिवासो अवक्रमुः । ते नो अव्रत । शतधारो अयं मणिः । तेनो अवन्तु । कुशिकासो अवस्यवः ॥ **सुपां सुलुक्पूर्वसवर्णाच्छेया-**

डाड्यायाजालः ।७।१।३९। ऋजवः सन्तु पन्थाः । पन्थान इति प्राप्ते । परमे व्योमन् । व्योमनीति प्राप्ते । धीती । मती । सुष्टुती । धीत्या । मत्या । सुष्टुत्येति प्राप्ते पूर्वसवर्णः । या सुरथा रथीतमा । यौ सुरथाविति प्राप्ते आ । नताद् ब्राह्मणम् । नतमिति प्राप्ते आत् । या देव विद्मतात्वा । यमिति प्राप्ते । नयुष्मे वाजबन्धवः । अस्मे इन्द्रा बृहस्पती । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठचोच्यावयतात् । आङो ड्या । साधुया । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्त इति प्राप्ते आल् ॥ **(इयाडियाजीकाराणामुपसंख्यानम्)** । उर्विया । उरुणेति प्राप्ते इया । सुक्षेत्रिया । सुक्षेत्रिणेति प्राप्ते डियाच् । 'दृतिं न शुष्कं सरसी शयानम्' । सरस्यामिति प्राप्ते ई ॥ **आज्जसेरसुक्** ।७।१।५०। ब्राह्मणासः ॥ **(तन्वादीनां वेयनवङौ ।)** तन्वं पुषेम । तनुवं पुषेम । विष्वं पश्य । विषुवं पश्य । स्वर्गो लोकः । सुवर्गो लोकः । त्र्यम्बकम् । त्रियम्बकम् । वरेण्यम् । वरेणियम् । 'अतो भिस ऐस्' ॥ **बहुलं छन्दसि** ।७।१।१०। अग्निर्देवेभिः ॥ **मन्त्रेष्वाङ्यादेरात्मनः** ।६।४।१४१। आत्मन्शब्दस्यादेर्लोप आङि । त्मना देवेषु । अपांभि ॥ **(मासश्छन्दसीति वक्तव्यम्)** माद्भिः । शरद्भिः ॥ **प्रसमुपोदः पादपूरणे** ।८।१।६। एषां द्वे स्तः । प्रप्रायमग्निः । संसमिद्युवसे । उपोपमे परामृश । किन्नो दुदुहर्षसे ॥ **षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु** ।८।३।५३। विसर्गस्य सः स्यात् । वाचस्पतिं विश्वकर्माणम् । दिवस्पुत्राय सूर्याय । दिवसस्पृष्टं भन्दमानः । तमसस्पारमस्य । परिवीत इळस्पदे । दिवस्पयो दिधिषाणाः । रायस्पोषं यजमानेषु धत्तन । इति वैदिकप्रक्रिया ॥

अथ स्वरप्रक्रिया ।

धातोः ।६।१।१६२। अन्त उदात्तः स्यात् ॥ **अनुदात्तं पदमेकवर्जम्** ।६।१।१५८। परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतन्नः । अत्र 'सनाद्यन्ता धातवः' इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः । शिष्टमनुदा-

त्तम् ॥ **उदात्तादनुदात्तस्य स्वरितः** ।८।४।६६। इति तकाराकारः स्वरितः ॥ **स्वरितात्संहितायामनुदात्तानाम्** ।१।२।३९। एकश्रुतिः स्यात् । इति नकाराकारः प्रचयः ॥ **अनुदात्तस्य च यत्रोदात्तलोपः** ।६।१।१६१। यस्मिन्ननुदात्ते उदात्तो लुप्यते तस्योदात्तः । देवीं वाचम् । अत्र ङीबुदात्तः ॥ **आद्युदात्तश्च** ।३।१।३। प्रत्ययस्याद्युदात्तः स्यात् । कर्तव्यम् ॥ **अनुदात्तौ सुप्पितौ** ।३।१।४। पूर्वस्यापवादः । यज्ञस्य । न यो युच्छति । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ॥ **चितः** ।६।१।१६३। अन्त उदात्तः स्यात् ॥ **(चितः सप्रकृतेर्बह्वकजर्थम्)** । चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे । यके सरस्वतीम् । तकत्सुते ॥ **तद्धितस्य** ।६।१।१६४। चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थम् । कौञ्जायनः । **कितः** ।६।१।१६५। कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ॥ **तित्स्वरितम्** ।६।१।१८५। क्व नूनम् ॥ **उपोत्तमं रिति** ।६।१।२१७। रित्प्रत्ययान्तस्योपोत्तममनुदात्तं स्यात् । यदाहवनीये ॥ **ञ्नित्यादिर्नित्यम्** ।६।१।१९७। ञिदन्तस्य निदन्तस्य चादिरुदात्तः । यस्मिन्विश्वानि पौंस्या । पुंसः कर्मणि ब्राह्मणादित्वात्ष्यञ् । सुतेदधिष्व नश्चनः । चायतेरसुन् । चायतेरन्ने ह्रस्वश्चेति चकारादसुना नुडागमः ॥ **लिति** ।६।१।१९३। प्रत्ययात्पूर्वमुदात्तं स्यात् । चिकीर्षकः । अत्र ईकारस्योदात्तता । इत्यादिप्रयोगमनुसृत्यान्वाख्यातव्यम् । इति स्वरप्रक्रिया ।

एषा वरदराजेन बालानामुपकारिका ॥
अकारि पाणिनीयानां मध्यसिद्धान्तकौमुदी ॥ १ ॥
कृतिर्वरदराजस्य मध्यसिद्धान्तकौमुदी ॥
तस्याः संख्या तु विज्ञेया खबाणकरवह्निभिः ॥ २ ॥

इति श्रीवरदराजकृता मध्यसिद्धान्तकौमुदी समाप्ता ॥

॥ अथ लिङ्गानुशासनम् ॥

॥ * ॥ **लिङ्गम्** । **स्त्री** । अधिकारसूत्रे एते ॥ **ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः** ।१। एते पञ्चैव स्त्रीलिङ्गाः ॥ **अन्यूप्रत्ययान्तो धातुः** ।२। अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः ॥ **मिन्यन्तः** ।३। मिनिप्रत्ययान्तः स्त्रियाम् । भूमिः । ग्लानिः ॥ **क्तिन्नन्तः** ।४। कृतिरित्यादि ॥ **ईप्रत्ययान्तश्च** ।५। लक्ष्मीः ॥ **ऊङाबन्तश्च** ।६। कुरूः । अजा ॥ **य्वन्तमेकाक्षरम्** ।७। स्त्रीः । भूः ॥ **विंशत्यादिरानवतेः** ।८। इयं विंशतिः ॥ **तलन्तः** ।९। शुक्लता ॥ **भाःस्रुग्दिगुष्णिगुपानहः** ।१०। इयं भा ॥ **स्थूणोर्णे नपुंसके च** ।११। स्थूणा । स्थूणम् ॥ **शष्कुलिराजिकुट्यशनिवर्तिभ्रुकुटित्रुटिवलिपङ्क्तयः** ।१२। एते स्त्रियां स्युः । इयं शष्कुलिः ॥ **अप्सुमनस्समासिकतावर्षाणां बहुत्वं च** ।१३। अबादीनां पञ्चानां स्त्रीत्वं स्याद्बहुत्वं च । आप इमाः ॥ **ताराधाराज्योत्स्नादयश्च** ।१४। इयं तारा ॥ इति स्त्र्यधिकारः ॥

पुमान् । अयमधिकारः ॥ **घञबन्तः** ।१। पाकः । करः । भावार्थ एवेदम् ॥ **घाजन्तश्च** ।२। विस्तरः । चयः ॥ **भयलिङ्गभगपदानि नपुंसके** ।३। भयमित्यादि ॥ **नङन्तः** ।४। पुंसि स्यात् । यज्ञ इत्यादि ॥ **याच्ञा स्त्रियाम्** ।५। पूर्वस्यापवादः ॥ **क्यन्तो घुः** ।६। आधिः । प्रधिः ॥ **इषुधिः स्त्री च** ।७। चात्पुंसि । इयमयं वा इषुधिः ॥ **द्यौः स्त्रियाम्** ।८। **क्रतुपुरुषकपोलगुल्फमेघाभिधानानि** ।९। क्रतुरध्वरः ॥ **अभ्रं नपुंसकम्** ।१०। पूर्वस्यापवादः ॥ **उदन्तः** ।११। अयं पुंसि स्यात् । प्रभुः । विभुः ॥ **धेनुरज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम्** ।१२। इयं धेनुः ॥ **रुत्वन्तः** ।१३। मेरुः । सेतुः ॥ **दारुकसेरुजतुवस्तुमस्तूनि नपुंसके च** ।१४। इदं दारु । दारुः ॥ **सक्तुर्नपुंसके च** ।१५। सक्तु । सक्तुः । **अदन्त** इत्यधिकृत्य ॥ **कोपधः** ।१६। कोपधोकारान्तः पुंसि स्यात् । स्तबकः । कल्कः ॥ **चिबुकादीनि नपुंसके** ।१७। चिबुकम् ॥ **टोपधः** ।१८। अदन्तः पुंसि । घटः । पटः ॥ **किरीटादीनि नपुंसके च** ।१९। किरीटम् । किरीटः ॥ **णोपधः** ।२०। अदन्तः पुंसि । गणः । पाषाणः ॥ **ऋणादीनि नपुं-**

सके ।२१। ऋणम् ॥ **कार्षापणादीनि नपुंसके च** ।२२। चात्पुंसि ॥ **थोपधः** ।२३। अदन्तः पुंसि । रथः । यूथः ॥ **नोपधः** ।२४। अदन्तः पुंसि । इनः । फेनः ॥ **जघनादीनि नपुंसके** ।२५। जघनम् ॥ **पोपधः** ।२६। अदन्तः पुंसि । दीपः पर्पः ॥ **पापादीनि नपुंसके** ।२७। पापम् ॥ **शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च** ।२८। चात्पुंसि ॥ **भोपधः** ।२९। कुम्भः । सरभः ॥ **तलभं नपुंसकम्** । ३०। **जृंभन्नपुंसके च** ।३१। **मोपधः** ।३२। होमः । धर्मः । **रुक्मादीनि नपुंसके** ।३३। इदं रुक्ममित्यादि ॥ **संग्रामादीनि नपुंसके च** ।३४। चात्पुंसि । संग्रामः । संग्रामम् ॥ **योपधः** ।३५। हयः । समयः ॥ **किसलयादीनि नपुंसके** ।३६। **गोमयादीनि नपुंसके च** ।३७। **रोपधः** ।३८। क्षुरः । खुरः । अङ्कुरः ॥ **द्वारादीनि नपुंसके** ।३९। इदं द्वारम् ॥ **शुक्रमदेवतायाम्** ।४०। देवतायां तु शुक्रः ॥ **षोपधः** ।४१। वृषः । वृक्षः ॥ **शिरीषादीनि नपुंसके** ।४२। इदं शिरीषम् ॥ **सोपधः** ।४३। वायसः । महानसः ॥ **पनसबिसबुससाहसानि नपुंसके** ।४४। **चमसादीनि नपुंसके च** ।४५। चात्पुंसि ॥ **कंसं चाप्राणिनि** ।४६। कंसः ॥ **कंसं वा पानपात्रम्** ।४७। प्राणिनि तु कंस औग्रसेनिः ॥ **रश्मिदिवाभिधानानि** ।४८। अत इति निवृत्तम् ॥ **दीधितिः स्त्रियाम्** ।४९। **दिनाहनी नपुंसके** ।५०। दिनं अहः ॥ **मानाभिधानानि** ।५१। कुडवः । **द्रोणाढकौ नपुंसके च** ।५२। चात्पुंसि ॥ **खारीमानिके स्त्रियाम्** ।५३। इयं खारिः ॥ **दाराक्षतलाजासूनां बहुत्वं च** ।५४। इमे दाराः ॥ **मरुद्गरुत्तरदृत्विजः** ।५५। अयं मरुत् ॥ **ध्वजगजमुञ्जपुञ्जाः** ।५६। एते पुंसि ॥ **वंशांशपुरोडाशाः** ।५७। अयं वंशः ॥ **ह्रदकन्दकुन्दबुद्बुदशब्दाः** ।५८। अयं ह्रदः ॥ **अर्घपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः** ।५९। अयमर्घः ॥ **सारथ्यतिथिकुक्षिबस्तिपाण्यञ्जलयः** ।६०। **पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः** ।६१। अयं पल्लव इत्यादि ॥ **ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिवलिकौलिमौलिरविकविकपिमुनयः** ।६२।

एते पुंसि स्युः । अयमृषिः ॥ **हस्तकुन्तान्तव्रातवातदूतधूर्तसूतचूतमुहूर्ताः** ।६३। एते पुंसि । अयं हस्त इत्यादि । इति पुंलिङ्गाधिकारः ॥

नपुंसकम् । अयमधिकारः ॥ **भावे ल्युडन्तः** ।१। ज्ञानम् । हसनम् । भावे किम् । पचनः ॥ **निष्ठा च** ।२। भावे या निष्ठा तदन्तं क्लीबं स्यात् । गीतम् ॥ **त्वष्यञौ तद्धितौ** ।३। शुक्लत्वम् । शौक्ल्यम् । षित्वसामर्थ्यात्पक्षे स्त्रीत्वे ङीष् । चातुरी ॥ **कर्मणि च ब्राह्मणादिगुणवचनेभ्यः** ।४। ब्राह्मण्यम् ॥ **यद्यढग्यगञण्वुञ्छाश्च भावकर्मणि** ।५। एतानि क्लीबानि । स्तेयम् । सख्यम् । कापेयम् । सैनापत्यम् । औष्ट्रम् । द्वैहायनम् । पितापुत्रकम् । अच्छावाकीयम् ॥ **अव्ययीभावः** ।६। अधिहरि ॥ **द्वन्द्वैकत्वम्** ।७। पाणिपादम् ॥ **अनल्पे छाया** ।८। शरच्छायम् ॥ **इसुसन्तः** ।९। हविः । सर्पिः । धनुः ॥ **अर्चिः स्त्रियां च** ।१०। इदमियं वार्चिः ॥ **छदिः स्त्रियामेव** ।११। इयं छदिः ॥ **मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि** ।१२। एषामभिधायकानि क्लीबे स्युः । मुखमाननं वक्त्रम् इत्यादि ॥ **सीरार्थौदनाः पुंसि** ।१३। **वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च** ।१४। चात् क्लीबे ॥ **अटवी स्त्रियाम्** ।१५। पूर्वस्येयं त्रिसूत्री बाधिका ॥ **लोपधः** ।१६। कुशलम् ॥ **शीलादीनि पुंसि च** ।१७। चात् क्लीबे । शीलम् ॥ **शतादिः संख्या** ।१८। शतम् । सहस्रम् ॥ **शतायुतप्रयुताः पुंसि च** ।१९। **लक्षा कोटिः स्त्रियाम्** ।२०। इयं लक्षा ॥ **सहस्रः पुंसि** ।२१। **मन् द्व्यच्कोऽकर्तरि** ।२२। मन्प्रत्ययान्तो द्व्यच्कः पुंसि स्यात् चात् क्लीबे नतु कर्तरि । वर्मा । वर्म । अकर्तरि किम् । ददातीति दामा । **ब्रह्मन्पुंसि च** ।२३। अयं ब्रह्मा । इदं ब्रह्म ॥ **सामरोमणी क्लीबे** ।२४। पूर्वस्यापवादः ॥ **असन्तो द्व्यच्कः** ।२५। यशः । मनः । तपः । अप्सराः ॥ **स्त्रियाम्** ।२६। एता अप्सरसः । **त्रन्नन्तः** ।२७। पत्रम् । छत्रम् ॥ **यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव** ।२८। इति नपुंसकाधिकारः ॥

स्त्रीपुंसयोः ।१। अयमधिकारः ॥ **गोमणियष्टिमुष्टिपाटलिबस्तिशाल्मलित्रुटिमसिमरीचयः** ।२। इयमयं वा गौः ॥ **अपत्यार्थतद्धिते** ।३। औपगवः । औपगवी । इति स्त्रीपुंसाधिकारः ॥

पुंनपुंसकयोः । अधिकारोयम् । **घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः** ।१। अयं घृतः । इदं घृतम् । **कबन्धौषधायुधान्ताः** ।२। स्पष्टम् । **दण्डमण्डखण्डशवसैंधवपार्श्वकाशाङ्कुशकुलिशाः** ।३। दण्डः । दण्डम् ॥ इति पुंनपुंसकाधिकारः ॥

अव्ययमवशिष्टलिङ्गम् ।१। **कतियुष्मदस्मदः** ।२। **ष्णान्ता संख्या । शिष्टा परवत्** ।३। एकः पुरुषः । एका स्त्री । एकं कुलम् ॥ **गुणवचनम्** ।४। शुक्लः पटः ॥ शुक्ला पटी । शुक्लं वस्त्रम् ॥ **कृत्याश्च** ।५। **करणाधिकरणयोर्ल्युट् च** ।६। **सर्वादीनि सर्वनामानि** ।७। स्पष्टार्थेयं त्रिसूत्री ।

इति श्रीवरदराजदीक्षितविरचितपाणिनीयलिङ्गानुशासन-
सारभूता लिङ्गानुशासनसूत्रवृत्तिः समाप्ता ॥

श्रीः ।

मध्यकौमुदीस्थसूत्राणामकारादिवर्णक्रमः ।

अइउण् १ ऋऌक् २ एओङ् ३ ऐऔच् ४ हयवरट् ५ लण् ६ ञमङणनम् ७ झभञ् ८ घढधष् ९ जबगडदश् १० खफछठथचटतव् ११ कपय् १२ शषसर् १३ हल् १४ । इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि ।

निर्णयसागरयन्त्रालये विक्रेयानि संस्कृतपुस्तकानि.

मू. मा. व्य.

अष्टाध्यायीसूत्रपाठः—पाणिनिमुनिप्रणीतः... ... ... ८≡ ८॥

धातुरूपावलिः— ... ... ८≡ ८॥

पातञ्जलमहाभाष्यम्—(नवाह्निकम् ।) कैयटप्रणीतप्रदीपेन नागेशकृतोद्द्योतेन पायगुण्डेकृतछायया च परिवृतम् । श्रीवाराणस्यादिनगरेषु विहितमुद्रणमपीदं नवाह्निकभाष्यमविभक्तविषयतया साहायकमिवाचरति दुर्बोधतायां विषयगाम्भीर्यस्येत्याकर्ण्य विविधविचक्षणमुखात्, संजातसुविभक्तमुद्रणोत्साहेन मयैतत् पूर्वपक्षि–सिद्धान्त्येकदेशि–सिद्धान्तयुक्तिभिस्तदन्तर्गतैरवान्तरविषयैश्च संविभज्य संयोज्य च यथास्वं शिरोलेख्ये–(हेडिंग)न संविभक्तविषयसूचकेन, विभूष्य च कृतसंविभागप्रदीपोद्द्योतयोरधस्तात् संनिवेशनेन मुद्रितम् । येनास्यानतिशिक्षिता अपि रहस्यमवगच्छेयुः । पायगुण्डे इत्युपाभिधनागेशछात्रप्रवरकृतछायायास्तु प्रथमोऽयं मुद्रणशालाप्रवेशः । इयमत्र टिप्पणीरूपं प्रतिलम्भिता.... ... ५ ।≡

प्राकृतमञ्जरी—श्रीमत्कात्यायनमुनिप्रणीतप्राकृतसूत्रवृत्तिः । संस्कृतनाटकादिप्रबन्धेषु नव्यादिपात्रेषु प्राकृतभाषा प्रयुक्तोपलभ्यते । सा किल मागधी–शौरसेनी–पैशाचीत्यादिभेदेन षोढा प्रविभक्ता प्राचीनैः प्राकृतभाषाव्याकर्तृभिः प्राकृतकल्पलतिकाकारादिभिः । तेष्वन्यतमस्य प्राथमकल्पिकस्य प्राकृतभाषाभेदस्येयं परिचायिकास्माभिर्भूयसायासेन संपाद्य मुद्रितास्ति ... ... ।· ८॥

रामचन्द्रिका—संस्कृतशब्दरूपावलिः, गुञ्जीकरकृता. ... ... ।· ८॥

लघुसिद्धान्तकौमुदी—श्रीवरदराजविरचिता, टिप्पण्या सूत्राणामकारादिकोशेन च सहिता. ... ... ।= ८–

लघुधातुरूपसंग्रहः—अत्र प्राचीनपण्डितवरसुबोधशास्त्रिप्रणीताः सोपसृष्टधात्वर्थादर्शनामिकाः कारिकाः सव्याख्याः लकारार्थनिरूपणं च विद्यते । तथा च धातूनां लक्षणानि, अनुबन्धप्रयोजनानि, उपसर्गार्थनिरूपणं च. ... ... ८≡ ८॥

शब्दरूपावलिः—गुञ्जीकरकृता. ... ... ℴ–॥ ℴ॥

समासचक्रम् ... ... ℴ– ℴ॥

सारस्वतव्याकरणं पूर्वार्धम्—वस्त्रबद्धम्. ... ... ·।– ℴ–

सारस्वतव्याकरणं वृत्तित्रयात्मकम्—इदं पुस्तकं प्राचीनहस्तलिखितपुस्तकान्येकीकृत्य संशोधय्य च मुद्रितम् । केवलं वस्त्रबद्धपुस्तकस्य. ... ... ·।।।· ℴ=

सारस्वतव्याकरणम्—वृत्तित्रयात्मकम्—पत्रमात्रबद्धम्... ... ·॥= ℴ–॥

सारस्वतव्याकरणम्—चन्द्रकीर्तिप्रणीतव्याख्यासहितम् (वृत्तित्रयात्मकम्.) ... ... २॥ ·।·

सारस्वतव्याकरणम्—चन्द्रकीर्तिव्याख्यासहितम् । पूर्वार्धम्. ... १ ℴ–

सारस्वतव्याकरणम्—चन्द्रकीर्तिव्याख्यासहितम् । उत्तरार्धम् ... १॥ ·।·

सारस्वतपूर्वपक्षावलिः. ... ... ℴ=॥ ℴ॥

सिद्धान्तकौमुदी—भट्टोजिदीक्षितकृता, अष्टाध्यायी, सूत्रपाठः, गणपाठः, धातुपाठः, लिङ्गानुशासनं, शिक्षा, सूत्रानुक्रमणी चेत्येतैः सहिता. ... ... २। ·।–

सिद्धान्तकौमुदी (तत्त्वबोधिनीसमाख्यव्याख्यासंवलिता.)—इयं चोत्तरकृदन्तान्तं श्रीमत्परमहंसपरिव्राजकाचार्य**ज्ञानेन्द्रसरस्वती**भिर्विरचित–**तत्त्वबोधिनी**संवलिता, उत्तरत्र, स्वरवैदिकीप्रकरणयोस्तु **श्रीमज्जयकृष्ण**विरचिता सुबोधिनी, **लिङ्गानुशासनो**परि भैरवमिश्रविरचित**भैरवी**टीका च वर्तते । ग्रन्थान्ते च पाणिनीय–**शिक्षा, सूत्रपाठः, गणपाठः, धातुपाठः, लिङ्गानुशासनं** चेति परिशिष्टानि अकाराद्यनुक्रमेण **कौमुदीगताष्टाध्यायी** सूत्राणां पृष्ठाङ्कसूत्राङ्क–सूची, **वार्तिक-गणसूत्र-परिभाषाणां** समुचितसूची, **धातूनां** पृष्ठाङ्कसूची, **उणादिसूत्र**सूची **फिट्सूत्र**सूचीति कोशपञ्चकं च संगृहीतम्. ... ... ४। ·।।।·

इमान्यन्यानि च पुस्तकान्यस्मत्समीपे मू. व्ही. पी. द्वारा वा मिलिष्यन्ति.

पांडुरंग जावजी,

निर्णयसागरमुद्रणालयाध्यक्षः,

मुंबई.